KISHKINDHAKANDAM

OF

SRIMADRAMAYANAM



MADRAS:
V. RAMASWAMY SASTRULU & SONS
292, Esplanade.
1929.
All Rights Reserved.

PRINTED AT
THE 'VAVILLA' PRESS,
MADRAS.—1929.

॥ श्रीरस्तु ॥

श्रीमद्वाल्मीकिरामायणे

॥ किष्किन्धाकाण्डः ॥



चेन्नपुर्यां

वाविळ्ळ रामस्वामिशास्त्रुलु अण्ड् सन्स्

इत्येतैः प्रकटितः

१९२९.

All Rights Reserved.

चेन्नपुरीस्थे
वाविळ्ळमुद्रणालये
सम्मुद्रितः.

॥ श्रीरामायण किष्किन्धाकाण्ड फलश्रुतिः ॥

सुग्रीवसख्य मारभ्य यावद्वालिनिषूदनम् ।
श्रुत्वा विजयमाप्नोति मुच्यते जारदोषतः ॥ १

दण्डादन्यं न पश्यामीत्यत्रैकादश मक्षरम् ।
श्रुत्वा मर्त्य स्स्वप्रकाशो लक्ष्मीलोक मवाप्नुयात् ॥ २

अभिषेकञ्च रामेण रुमायाः प्राप्ति मुत्तमाम् ।
सुग्रीवस्य जयं श्रुत्वा राज्यलाभमवाप्नुयात् ॥ ३

वाक्य मात्महितं चैवेत्यत्र द्वादशवर्णकम् ।
श्रुत्वा रामप्रसादेन सोऽमृतत्वमवाप्नुयात् ॥ ४

किष्किन्धाकाण्डपठनात्तदर्थश्रवणादपि ।
सर्वदा सर्वलोकेषु कामचारो भवेन्नरः ॥ ५

॥ श्रीः ॥

स्मार्तादीनां सर्वेषां श्रीरामायणपारायणादौ ॥ कर्तव्यपूजाविधानम् ॥

आचम्य । प्राणानायम्य । ममोपात्त....शुभे शोभने मुहूर्ते अस्यां शुभतिथौ श्रीसीतालक्ष्मणभरतशत्रुघ्न हनुमत्समेत श्रीरामचन्द्र-देवताप्रीत्यर्थं यावच्छक्तिध्यानावाहनादिषोडशोपचारपूजां करिष्ये ॥ आदौ निर्विघ्नेन परिसमाप्त्यर्थं गणाधिपतिपूजां करिष्ये ॥ तदंगत्वेन कलशपूजां करिष्ये ॥ कलशपूजां गणपतिपूजांच कृत्वा ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यांतं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

ततश्श्रीमत्कोशोपरि श्रीरामध्यानावाहनादिनैवेद्यांतपूजा-विधेया ॥ श्रीरामचन्द्रदेवताभ्यां नमः ॥ ध्यानावाहनादिषोडशोप-चारैपूजां च कृत्वा ॥

॥ श्रीमद्रामायणपारायणारम्भक्रमः ॥

सद्गुरुसकाशाल्लब्धोपदेशोवक्ष्यमाणरीत्या श्रीरामायणपारायणं कुर्यात् - देशकालौ संकीर्त्य—

अस्य श्रीरामायणमहामंत्रस्य वाल्मीकि र्भगवान् ऋषिः - अनुष्टुप्छन्दः - श्रीसीतालक्ष्मणभरतशत्रुघ्न हनुमत्समेत श्रीरामचन्द्रो देवता - रां वीजं - श्रीं शक्तिः - मं कीलकं - मम श्रीसीतालक्ष्मण-भरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रप्रसादसिद्ध्यर्थे पारायणजपे विनि-

योगः - रां अंगुष्ठाभ्यान्नमः - रीं तर्जनीभ्यां स्वाहा - रूं मध्यमाभ्यां वषट् - रैं अनामिकाभ्यां हुं - रौं कनिष्ठिकाभ्यां वौषट् - रः करतलकरपृष्ठाभ्यां फट् - रां हृदयाय नमः - रीं शिरसे स्वाहा - रूं शिखायै वषट् - रैं कवचाय हुं - रौं नेत्रत्रयाय वौषट् - रः अस्त्राय फट् ॥ लोकत्रयेण दिग्बंधः ॥

ध्यानम् :—

कालांभोधरकांतिकांतमनिशं वीरासनाध्यासिनं
मुद्रां ज्ञानमयीं दधान मपरं हस्तांबुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यंतं मकुटांगदादिविविधाकल्पोज्ज्वलांगं भजे ॥

॥ अथ मानसिकपूजा ॥

लं पृथिव्यात्मने श्रीरामचन्द्रपरब्रह्मणे गंधं समर्पयामि - हं आकाशात्मने श्रीरामचन्द्रपरब्रह्मणे पुष्पं समर्पयामि - यं वाय्वात्मने श्रीरामचन्द्रपरब्रह्मणे धूपमाघ्रापयामि - रं अग्न्यात्मने श्रीरामचन्द्रपरब्रह्मणे दीपं दर्शयामि - वं अमृतात्मने श्रीरामचन्द्रपरब्रह्मणे अमृतोपहारं समर्पयामि - सं सर्वात्मने श्रीरामचन्द्रपरब्रह्मणे सर्वोपचारपूजास्समर्पयामि - इति मानसिकपूजा ॥

मूलमंत्रः—

धर्मात्मा सत्यसंधश्च रामो दाशरथि र्यदि ।
पौरुषे चा प्रतिद्वंद्वश्शरैनं जहि रावणिम् ॥

इति यथाशक्ति जपित्वा श्रीरामायणपारायणं कुर्यात् ॥ अनंतरं पुनः ध्यानं मानसिकपूजां हृदयादिन्यासं च कुर्यात् - लोकत्रयेण दिग्विमोकः ॥

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिं भवतु मे देव ! त्वत्प्रसादा द्रघूद्वह ! ॥

श्रीवैष्णवानां

॥ श्रीमद्रामायणपठनोपक्रमानुसंधेयक्रमः ॥

प्रथमतः(रामानुज)श्रीशैलेशेत्यादि स्वस्वसंप्रदाय निर्वाहकाचार्यानुसंधानम्। ततः 'लक्ष्मीनाथे' त्यारभ्य 'प्रणतोऽस्मिनित्य' मित्यंतम्। अनंतरं श्रीशैलपूर्णविषयम् 'पितामह'स्येति श्लोकमारभ्य श्रीभाष्यकारप्रभृतिस्वाचार्यपर्यंत विषया स्सांप्रदायिकश्लोका अनुसंधेयाः ॥ वद्वा श्रीधरादिस्वाचार्यपर्यंताः प्रतिव्यक्तिश्लोका अनुसंधेयाः ॥

ततः —

कूजंतं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ १
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन्रामकथानादं को न याति परां गतिम् ॥ २
यःपिबन्सततं रामचरितामृतसागरम् ।
अतृप्त स्तं मुनिं वन्दे प्राचेतस मकल्मषम् ॥ ३
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ४

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीश मक्षहंतारं वन्दे लङ्काभयंकरम् ॥ ५
मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ६
उल्लङ्घ्य सिन्धोस्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।
आदायतेनैव ददाह लङ्कां नमामि तं प्राञ्जलि राञ्जनेयम् ॥ ७
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ८
यत्रयत्र रघुनाथकीर्तनं तत्रतत्र कृतमस्तकाञ्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ९
वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥ १०
तदुपगतसमाससन्धियोगं समममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ ११
श्रीराघवं दशरथात्मज मप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहु मरविन्ददळायताक्षं रामं निशाचरविनाशकरं नमामि ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १३

ततो यथाशक्ति श्रीकोशोपरि भगवदाराधनं कर्तव्यम् ॥

॥ पारायणसमापनक्रमः ॥

एवमेतत्पुरावृत्त माख्यानं भद्र मस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ २

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितो ब्राह्मणा स्सन्तु निर्भयाः ॥ ३

कावेरी वर्धतां काले काले वर्षतु वासवः ।
श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् ॥ ४

स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्य श्शुभमस्तु नित्यं लोका स्समस्ता स्सुखिनो भवन्तु ॥

मङ्गळं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गळम् ॥ ६

वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गळम् ॥ ७

विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गळम् ॥ ८

पितृभक्तायसततं भ्रातृभि स्सहसीतया ।
नन्दिताखिललोकाय रामभद्राय मङ्गळम् ॥ ९

त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।
सेव्याय सर्वयमिनां धीरोदाराय मङ्गळम् ॥ १०

सौमित्रिणा च जानक्या चापबाणासिधारिणे ।
संसेव्याय सदाभक्त्या स्वामिने मम मङ्गळम् ॥ ११

दण्डकारण्यवासाय खण्डितामरशत्रवे ।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गळम् ॥ १२

सादरं शबरीदत्तफलमूलाभिलाषिणे ।
सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गळम् ॥ १३

हनुमत्समवेताय हरीशाभीष्टदायिने ।
वालिप्रमथनायास्तु महाधीराय मङ्गळम् ॥ १४

श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे ।
जितराक्षसराजाय रणधीराय मङ्गळम् ॥ १५

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गळम् ॥ १६

मङ्गळाशासनपरै र्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वै राचार्यै स्सत्कृतायास्तु मङ्गळम् ॥ १७

[कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मनावा प्रकृते स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥]

ततः 'पितामह' स्येत्यारभ्य स्वाचार्यान्ताश्श्लोका अनुसन्धेयाः ॥

श्रीस्मार्तमध्वादीनां श्रीमद्रामायण
॥ पठनोपक्रमानुसन्धेयक्रमः ॥

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १

वागीशाद्या स्सुमनस स्सर्वार्थाना मुपक्रमे ।
यं नत्वा कृतकृत्यास्युस्तं नमामि गजाननम् ॥ २

ततः श्रीमच्छङ्कराचार्यादि गुरुपरम्परानुसन्धेया ॥

दोर्भिर्युक्ता चतुर्भि स्स्फटिकमणिमयीं मक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ ३

कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्यकविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ४

वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥ ५

यः पिबन् सततं रामचरितामृतसागरम् ।
अतृप्तस्तं मुनिं वन्दे प्राचेतस मकल्मषम् ॥ ६

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ७

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ८

उल्लङ्घ्यसिन्धो स्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलि राञ्जनेयम् ॥ ९
आञ्जनेय मतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ १०
यत्रयत्र रघुनाथकीर्तनं तत्रतत्र कृतमस्तकाञ्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ११
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १२
यः कर्णाञ्जलिसंपुटै रहरह स्सम्यक्पिबत्यादरा-
द्वाल्मीके र्वदनारविंदगलितं रामायणाख्यं मधु ।
जन्मव्याधिजराविपत्तिमरणै रत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान्विष्णोः पदं शाश्वतम् ॥ १३
तदुपगतसमाससन्धियोगं समधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ १४
वाल्मीकिगिरिसंभूता रामसागरगामिनी ।
पुनाति भुवनं पुण्या रामायणमहानदी ॥ १५
श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् ।
काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ १६
वेदवेद्ये परेपुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥ १७
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पक मासने मणिमये वीरासने सुस्थितम् ।

अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यःपरं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १८

वामे भूमिसुता पुरश्च हनुमान् पश्चात्सुमित्रासुत-
श्शत्रुघ्नो भरत श्च पार्श्वदलयो र्वाय्वादिकोणेषु च ।
सुग्रीव श्च विभीषण श्च युवराट्तारासुतो जाम्बवा-
न्मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ १९

नमोऽस्तु रामाय स लक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २०

[ततश्श्रीकोशोपरि श्रीरामावाहनादिनैवेद्यान्तपूजा विधेया पारायणावसाने च पुनः पूजा कर्तव्या ॥]

॥ पारायणसमाप्तनमस्कारासुसन्धेयक्रमः ॥

स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेनमार्गेण महींमहीशाः ।
गोब्राह्मणेभ्य श्शुभमस्तु नित्यं लोकास्समस्ता स्सुखिनो भवन्तु ॥ १

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितो ब्राह्मणा स्सन्तुनिर्भयाः ॥ २

अपुत्त्राः पुत्त्रिणस्सन्तु पुत्त्रिणस्सन्तु पौत्त्रिणः ।
अधना स्सधना स्सन्तुर्जीवन्तु शरदां शतम् ॥ ३

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैक मक्षरं प्रोक्तं महापातकनाशनम् ॥ ४

श्रृण्वन् रामायणं भक्त्या यः पादं पद मेव वा।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ ५

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ६

यन्मङ्गळं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत्तत्ते भवतु मङ्गळम् ॥ ७

यन्मङ्गळं सुपर्णस्य विनताऽकल्पयत्पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गळम् ॥ ८

मङ्गळं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजायसार्वभौमायमङ्गळम् ॥ ९

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिर्मङ्गळं प्रादात्तत्ते भवतु मङ्गळम् ॥ १०

त्रीन्विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गळं राम तत्ते भवतु मङ्गळम् ॥ ११

ऋतवस्सागराद्वीपा वेदा लोकादिशश्चते ।
मङ्गळानि महाबाहो दिशन्तु तव सर्वदा ॥ १२

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मनावा प्रकृतेस्स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीराघवायेति समर्पयामि ॥ १३

॥ श्रीगायत्रीरामायणम् ॥

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजित स्सम्यग्यथेन्द्रो विजयी पुरा ॥ २

विश्वामित्र स्स धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघव मब्रवीत् ॥ ३

तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ।
शयनीयं नरेन्द्रस्य तदासाद्यव्यतिष्ठत ॥ ४

वनवासं हि संख्याय वासांस्याभरणानिच ।
भर्तार मनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ ५

राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥ ६

निरीक्ष्य स मुहूर्तंतु ददर्श भरतो गुरुम् ।
उटजे राम मासीनं जटावल्कलधारिणम् ॥ ७

यदि बुद्धिः कृता द्रष्टु मगस्त्यं तं महामुनिम् ।
अद्यैव गमने बुद्धिं रोचयस्व महायशाः ॥ ८

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ ९

गच्छ शीघ्र मितोरामसुग्रीवंतं महाबलम् ।
वयस्यं तं कुरुक्षिप्रमितो गत्वाऽद्य राघव ॥ १०

देशकालौ प्रतीक्षस्व क्षममाणः प्रियाप्रिये ।
सुखदुःखसहः काले सुग्रीववशगोभव ॥ ११

वन्द्यास्तेतु तपस्सिद्धास्तपसावीतकल्मषाः ।
प्रष्टव्यास्तेऽपिसीतायाः प्रवृत्तिं विनयान्वितैः ॥ १२

स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।
विक्रमेण महातेजा हनूमान् मारुतात्मजः ॥ १३

धन्या देवा स्सगन्धर्वा स्सिद्धाश्च परमर्षयः ।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ १४

मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः ।
उपतस्थे विशालाक्षी प्रयताहव्यवाहनम् ॥ १५

हितं महार्थं मृदुपूर्वं संहितं व्यतीतकालायतिसंप्रतिक्षमम् ।
निशम्य तद्वाक्य मुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ १६

धर्मात्मा रक्षसां श्रेष्ठ स्संप्राप्तोऽयं विभीषणः ।
लंकैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ १७

यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।
स रामबाणाभिहतो भृशार्तश्चचाल चापंचमुमोच वीरः ॥ १८

यस्यविक्रममासाद्य राक्षसा निधनं गताः ।
तं मन्ये राघवं वीरं नारायण मनामयम् ॥ १९

नते ददृशिरे रामं दहन्तमरिवाहिनीम् ।
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥ २०

प्रणम्य देवताभ्यश्चब्राह्मणेभ्यश्च मैथिली ।
बद्धाञ्जलिपुटा चेद मुवाचाग्निसमीपतः ॥ २१

चलनात्पर्वतेन्द्रस्य गणा देवाश्च कम्पिताः ।
चचाल पार्वती चापितदाऽश्लिष्टामहेश्वरम् ॥ २२

दाराः पुत्त्राः पुरं राष्ट्रं भोगाच्छादनभाजनम् ।
सर्वमेवाविभक्तं नो भविष्यति हरीश्वरः ॥ २३

या मेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् ।
ता मेव रात्रिं सीताऽपि प्रसूता दारकद्वयम् ॥ २४

इदं रामायणं कृत्स्नंगायत्रीबीजसंयुतम् ।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २५

गायत्रीरामायणं संपूर्णम् ॥

॥ देवताप्रार्थना ॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्याये त्सर्वविघ्नोपशान्तये ॥ १

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाःपतये नमः ॥ २

॥ वाल्मीकिप्रार्थना ॥

कूजंतं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ १
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन् रामकथानादं कोनयाति परांगतिम् ॥ २

॥ आंजनेयप्रार्थना ॥

अंजनानंदनं वीरं जानकीशोकनाशनम् ।
कपीश मक्षहंतारं वन्दे लङ्काभयंकरम् ॥ १
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ २
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ३

॥ श्रीरामायणप्रशंसा ॥

श्रीमद्ब्रह्मतदेव बीज ममलं यस्याङ्कुर श्चिन्मयः
काण्डै स्सप्तभि रन्वितोऽतिविततो ऋष्यालवालोदितः ।
पत्त्रैस्तत्त्वसहस्रकै स्सुविलसच्छाखाशतैः पञ्चभिः
स्वात्मप्राप्तिफलप्रदो विजयते रामायणस्वस्तरुः ॥
यः कर्णांजलिसंपुटै रहरह स्सम्य क्पिबत्यादरा-
द्वाल्मीके र्वदनारविन्दगलितं रामायणाख्यं मधु ।
जन्मव्याधिजराविपत्तिमरणै रत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान्विष्णोःपदं शाश्वतम् ॥

वाल्मीकिगिरिसंभूता रामांभोनिधिसंगता ।
श्रीमद्रामायणी गंगा पुनातु भुवनत्रयम् ॥

॥ उमासंहितायां धर्मराजं प्रतिब्रह्मोक्तिः ॥

श्रीरामप्रातिपदिक मवशेनापि संगृणन् ।
मुक्तिं प्राप्नोति मनुजः किंपुन र्बुद्धिपूर्वकम् ॥ १
राशब्दोच्चारणादेव पातका देहपञ्जरात् ।
निर्यान्त्यायान्ति पापानि मवर्णादर्शनात्पुनः ॥ २
राशब्दोच्चारणे जाते वक्त्रात्पापं विगच्छति ।
मकारश्रवणे जाते भस्मीभावं गमिष्यति ॥ ३

॥ तत्रैव तृतीयाध्याये उमां प्रतिशिवोक्तिः ॥

रामेति रामचन्द्रेति रामभद्रेति वा मनुम् ।
यावज्जीवं जपन्मर्त्यो जीवन्मुक्तो न संशयः ॥ १
रामायणस्य माहात्म्यं वक्तुं वर्षशतैरपि । .
अशक्यं विस्तरा द्वक्तुं संक्षेपा द्वच्मि सांप्रतम् ॥ २
रामायणस्य वाक्यंवा पादंवा पदमेववा ।
भुक्त्यन्तेतु प्रयुंजानो ब्रह्मभूयाय कल्पते ॥ ३
रामायणकथामेव येशृण्वंति नरोत्तमाः ।
विधूतपापास्ते यान्ति ब्रह्मलोक मनामयम् ॥ ४

॥ तत्वसंग्रहरामायणे उत्तरकाण्डे एकविंशत्सर्गे द्वाविंशच्छ्लोकः ॥

संसारतापयुक्तानां जन्तूनां हतचेतसाम् ।
श्रीमद्रामायणाख्यानपीयूषं भेषजं स्मृतम् ॥ १

॥ श्रीरस्तु ॥

श्रीमद्रामायणे-किष्किन्धाकाण्डे

॥ प्रथमस्सर्गः ॥

स तां पुष्करणीं गत्वा पद्मोत्पलझषाकुलाम् ।
राम स्सौमित्रिसहितो विललापाकुलेन्द्रियः ॥ १
तस्य दृष्ट्वैव तां हर्षा दिन्द्रियाणि चकम्पिरे ।
स कामवश मापन्न स्सौमित्रि मिद मब्रवीत् ॥ २
" सौमित्रे ! शोभते पम्पा वैडूर्यविमलोदका ।
फुल्लपद्मोत्पलवती शोभिता विविधै र्द्रुमैः ॥ ३
सौमित्रे ! पश्य पम्पायाः काननं शुभदर्शनम् ।
यत्र राजन्ति शैलाभा द्रुमास्सशिखरा इव ॥ ४
मांतु शोकाभिसंतप्तं माधवः पीडयन्निवै ।
भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ५
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ।
व्यवकीर्णा बहुविधैः पुष्पै श्शीतोदका शिवा ॥ ६
नळिनै रपि संछन्नाह्यत्यर्थं शुभदर्शना ।
सर्पव्याळानुचरिता मृगद्विजसमाकुला ॥ ७
अधिकं प्रतिभात्येतन्नीलपीतं तु शाद्वलम् ।
द्रुमाणां विविधैः पुष्पैः परिस्तोमै रिवार्पितम् ॥ ८
[नाना प्रख्यातकुसुमै श्छन्ना भूर्भाति लक्ष्मण ! ॥]

पुष्पभारसमृद्धानि शिखराणि समन्ततः ।
लताभिः पुष्पिताग्राभि रुपगूढानि सर्वशः ॥ ९
सुखानिलोऽयं सौमित्रे! कालः प्रचुरमन्मथः ।
गन्धवत्सुरभिर्मासो जातपुष्पफलद्रुमः ॥ १०
पश्य रूपाणि सौमित्रे! वनानां पुष्पशालिनाम् ।
सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥ ११
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ १२
पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।
कुसुमैः पश्य सौमित्रे! क्रीडन्निव समन्ततः ॥ १३
विक्षिपन्विविधाञ्शाखानगानां कुसुमोत्कचाः ।
मारुत श्चलितस्थानै ष्षट्पदैरनुगीयते ॥ १४
मत्तकोकिलसन्नादै र्नर्तयन्निव पादपान् ।
शैलकन्दरनिष्क्रान्तः प्रगीतइव चानिलः ॥ १५
तेन विक्षिप्तात्यर्थं पवनेन समन्ततः ।
अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ १६
स एष सुखसंस्पर्शो वाति चन्दनशीतलः ।
गन्धमभ्यवहन्पुण्यं श्रमापनयनोऽनिलः ॥ १७
अमी पवनविक्षिप्ता विनदन्तीव पादपाः ।
षट्पदै रनुकूजन्तो वनेषु मधुगन्धिषु ॥ १८
गिरिप्रस्थेषु रम्येषु पुष्पवद्भि र्मनोरमैः ।
संसक्तशिखराश्शैला विराजन्ते महाद्रुमैः ॥ १९

पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः ।
अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ २०
पुष्पिताग्रां स्तु पश्येमान्कर्णिकारांत्समन्ततः ।
हाटकप्रतिसंछन्ना नरान्पीताम्बरानिव ॥ २१
अयं वसन्त स्सौमित्रे! नानाविहगनादितः ।
सीतया विप्रहीनस्य शोकसन्दीपनो मम ॥ २२
मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः ।
हृष्टः प्रवदमान श्च मामाह्वयति कोकिलः ॥ २३
एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे ।
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण! ॥ २४
श्रुत्वैतस्य पुराशब्दमाश्रमस्था मम प्रिया ।
मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥ २५
एवं विचित्राः पतगा नानारावविराविणः ।
वृक्षगुल्मलताः पश्य सम्पतन्ति ततस्ततः ॥ २६
विमिश्रा विहगाः पुम्भि रात्मव्यूहाभिनन्दिताः ।
भृङ्गराजप्रमुदिता स्सौमित्रे! मधुरस्वनाः ॥ २७
[तस्याः कूले प्रमुदिता श्शकुनास्सङ्घशस्त्विह ।]
नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतै रपि ॥ २८
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः ।
अशोकस्तबकाङ्गारष्षट्पदस्वननिस्वनः ॥ २९
मां हि पल्लवताम्रार्चि र्वसन्ताग्निः प्रधक्ष्यति ।
नाहितां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ॥ ३०

अपश्यतो मे सौमित्रे! जीवितेऽस्ति प्रयोजनम् ।
अयं हि दयित स्तस्याः कालो रुचिरकाननः ॥ ३१
कोकिलाकुलसीमान्तो दयिताया ममानघ! ।
मन्मथाऽयाससम्भूतो वसन्तगुणवर्धितः ॥ ३२
अयं मां धक्ष्यति क्षिप्रं शोकाग्नि र्नचिरा दिव ।
अपश्यत स्तां दयितां पश्यतो रुचिरद्रुमान् ॥ ३३
ममायमात्मप्रभवो भूय स्त्व मुपयास्यति ।
अदृश्यमाना वैदेही शोकं वर्धयते मम ॥ ३४
दृश्यमानो वसन्त श्च खेदसंसर्गदूषकः ।
मां ह्यद्य मृगशाबाक्षी चिन्ताशोकबलात्कृतम् ॥ ३५
सन्तापयति सौमित्रे! क्रूरश्चैत्रो वनानिलः ।
अमी मयूरा श्शोभन्ते प्रनृत्यन्त स्तत स्ततः ॥ ३६
स्वैः पक्षैः पवनोद्भूतै र्गवाक्षैः स्फाटिकै रिव ।
शिखिनीभिः परिवृता स्त एते मदमूर्छिताः ॥ ३७
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ।
पश्य लक्ष्मण नृत्यन्तं मयूर मुपनृत्यति ॥ ३८
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ।
तामेव मन्मथाविष्टो मयूरोऽप्युपधावति ॥ ३९
वितत्य रुचिरौ पक्षौ रुतै रुपहसन्निव ।
मयूरस्य वने नूनं रक्षसा न हृता प्रिया ॥ ४०
तस्मान्नृत्यति रम्येषु वनेषु सहकान्तया ।
मम त्वयं वने वासः पुष्पमासे सुदुस्सहः ॥ ४१

पश्य लक्ष्मण! संरागं तिर्यग्योनिगतेष्वपि ।
यदेषा शिखिनी कामाद्भर्तारं रमतेऽन्तिके ॥ ४२
मामप्येवं विशालाक्षी जानकी जातसम्भ्रमा ।
मदनेनाभिवर्तेत यदि नाऽपहृता भवेत् ॥ ४३
पश्य लक्ष्मण! पुष्पाणि निष्फलानि भवन्ति मे ।
पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ ४४
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ।
निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥ ४५
वदन्ति रावं मुदिता इशकुना स्सङ्गशः कलम् ।
आह्वयन्त इवान्योन्यं कामोन्मादकरामम ॥ ४६
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया ।
नूनं परवशा सीता सापि शोचत्यहं यथा ॥ ४७
नूनं नतु वसन्तोऽयं देशं स्पृशति यत्र सा ।
कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥ ४८
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।
किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥ ४९
श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी ।
नूनं वसन्त मासाद्य परित्यक्ष्यति जीवितम् ॥ ५०
दृढं हि हृदये बुद्धि र्मम सम्प्रति वर्तते ।
नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥ ५१
मयि भावस्तुवैदेह्या स्त्वतो विनिवेशितः ।
ममापि भावस्सीतायां सर्वथा विनिवेशितः ॥ ५२

एष पुष्पवहो वायु स्सुखस्पर्शो हिमावहः ।
तां विचिन्तयतः कान्तां पावकप्रतिमोमम ॥ ५३
सदा सुख महं मन्ये यं पुरा सहसीतया ।
मारुत स्सविना सीतां शोकं वर्धयते मम ॥ ५४
तां विना स विहङ्गो यः पक्षी प्रणदित स्तदा ।
वायसः पादपगतः प्रहृष्ट मभिनर्दति ॥ ५५
एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।
पक्षी मां तु विशालाक्ष्या स्समीप मुपनेष्यति ॥ ५६
शृणु लक्ष्मण! सन्नादं वने मदविवर्धनम् ।
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ ५७
विक्षिप्तां पवनेनैता मसौ तिलकमञ्जरीम् ।
षट्पद स्सहसाऽभ्येति मदोद्धूता मिव प्रियाम् ॥ ५८
कामिना मय मत्यन्त मशोक श्शोकवर्धनः ।
स्तवकैः पवनोत्क्षिप्तै स्तर्जयन्निव मां स्थितः ॥ ५९
अमी लक्ष्मण! दृश्यन्ते चूताः कुसुमशालिनः ।
विभ्रमोत्सिक्तमनस स्साङ्गरागा नरा इव ॥ ६०
सौमित्रे! पश्य पम्पाया श्चित्रासु वनराजिषु ।
किन्नरा नरशार्दूल! विचरन्ति तत स्ततः ॥ ६१
इमानि शुभगन्धीनि पश्य लक्ष्मण! सर्वशः ।
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ६२
एषाप्रसन्नसलिला पद्मनीलोत्पलायुता ।
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकान्विता ॥ ६३

जले तरुणसूर्याभै ष्षट्पदाहतकेसरैः ।
पङ्कजैश्शोभते पम्पा समन्तादभिसंवृता ॥ ६४
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा ।
[क्रौञ्चसारससंघुष्टा विचित्रकुसुमोत्करा] ॥ ६५
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ।
पवनाहतवेगाभि रूर्मिभि र्विमलेऽम्भसि ॥ ६६
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ! ।
पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम् ॥ ६७
अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ।
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् ॥ ६८
स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ।
शक्यो धारयितुं कामो भवेदद्यागतो मया ॥ ६९
यदि भूयो वसन्तो मां न हन्यात्पुष्पितद्रुमः ।
यानि स्म रमणीयानि तया सह भवन्ति मे ॥ ७०
तान्येवारमणीयानि जायन्ते मे तया विना ।
पद्मकोशपलाशानि दृष्ट्वादृष्टि र्हि मन्यते ॥ ७१
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ! ।
पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः ॥ ७२
निःश्वासइव सीताया वाति वायुर्मनोहरः ।
सौमित्रे ! पश्य पम्पाया दक्षिणे गिरिसानुनि ॥ ७३
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ।
अधिकं शैलराजोऽयं धातुभिस्सुविभूषितः ॥ ७४

विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ।
गिरिप्रस्थास्तु सौमित्रे! सर्वतस्सम्प्रपुष्पितैः ॥ ७५
निष्पत्रैः स्सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ।
पम्पातीररुहा श्चेमे संसक्ता मधुगन्धिनः ॥ ७६
मालतीमल्लिकाषण्डाः करवीरा श्च पुष्पिताः ।
केतक्य स्सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः ॥ ७७
माधव्यो गन्धपूर्णा श्च कुन्दगुल्मा श्च सर्वशः ।
चिरिबिल्वा मधूकाश्च वञ्जुळा वकुळा स्तथा ॥ ७८
चम्पका स्तिलकाश्चैव नागवृक्षा स्सुपुष्पिताः ।
नीपाश्च वरणा श्चैव खर्जूराश्च सुपुष्पिताः ॥ ७९
पद्मका श्चैव शोभन्ते नील शोका श्च पुष्पिताः ।
लोध्रा श्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः ॥ ८०
अङ्कोलाश्च कुरण्टा श्च पूर्णकाः पारिभद्रकाः ।
चूताः पाटलय श्चैव कोविदाराश्च पुष्पिताः ॥ ८१
सुचुळिन्दार्जुना श्चैव दृश्यन्ते गिरिसानुषु ।
केतकोद्दालका श्चैव शिरीषा शिंशुपा धवाः ॥ ८२
शाल्मल्यः किंशुका श्चैव रक्ताः कुरवका स्तथा ।
तिनिशा नक्तमाला श्च चन्दना स्सप्तच्छदास्तथा ॥ ८३
पुष्पिता न्पुष्पिताग्राभि र्लताभिः परिवेष्टितान् ।
द्रुमान्पश्येह सौमित्रे! पम्पाया रुचिरान्द्रुमान् ॥ ८४
वातविक्षिप्तविटपा न्यथासन्नान्द्रुमानिमान् ।
लता स्समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥ ८५

पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम् ।
वाति नैकरसास्वादसम्मोदित इवानिलः ॥ ८६
केचि त्पर्यायप्रकुसुमाः पादपा मधुगन्धिनः ।
केचिन्मुकुळसंवीताः श्यामवर्णा इवाऽबभुः ॥ ८७
इदं मृष्ट मिदं स्वादु प्रफुल्ल मिद मित्यपि ।
रागमत्तो मधुकरः कुसुमेष्वेव लीयते ॥ ८८
निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति ।
मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ ८९
इयं कुसुमसंघातै रुपस्तीर्णा सुखाकृता ।
स्वयं निपतितै र्भूमि श्शयनप्रस्तरैरिव ॥ ९०
विविधा विविधैः पुष्पै स्तैरेव नगसानुषु ।
विकीर्णैःपीतरक्ताहि सौमित्रे! प्रस्तराः कृताः ॥ ९१
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ।
पुष्पमासे हि तरव स्संघर्षा दिव पुष्पिताः ॥ ९२
आह्वयन्त इवान्योन्यं नगाष्षट्पदनादिताः ।
कुसुमोत्तंसविटपा श्शोभन्तेबहुलश्मण! ॥ ९३
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।
रमते कान्तया सार्धं काम मुद्दीपयन्मम ॥ ९४
मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम् ।
स्थाने जगतिविख्याता गुणास्तस्या मनोरमाः ॥ ९५
यदि दृश्येत सा साध्वी यदिचेह वसेमहि ।
स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम! ॥ ९६

नह्येवं रमणीयेषु शाद्वलेषु तया सह ।
रमतो मे भवेच्चिन्ता न स्पृहाऽन्येषु वा भवेत् ॥ ९७
अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः ।
काननेऽस्मिन्विना कान्तां चित्तमुन्मादयन्ति मे ॥ ९८
पश्य शीतजलां चेमां सौमित्रे! पुष्करायुताम् ।
चक्रवाकानुचरितां कारण्डवनिषेविताम् ॥ ९९
प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम् ।
अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः ॥ १००
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः ।
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ १०१
पश्य सानुषु चित्रेषु मृगीभिस्सहितान्मृगान् ।
मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ १०२
व्यथयन्तीव मे चित्तं संचरन्त स्ततस्ततः ।
अस्मिंत्सानुनि रम्ये हि मत्तद्विजगणायुते ॥ १०३
पश्येयं यदि तां कान्तां ततस्स्वस्ति भवेन्मम ।
जीवेयं खलु सौमित्रे! मया सह सुमध्यमा ॥ १०४
सेवते यदि वैदेही पम्पायाः पवनं सुखम् ।
पद्मसौगन्धिकवहं शिवं शोकविनाशनम् ॥ १०५
धन्या लक्ष्मण! सेवन्ते पम्पोपवनमारुतम् ।
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ॥ १०६
कथं धारयति प्राणान्विवशा जनकात्मजा ।
किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ॥ १०७

सीतया जनकं पृष्टः कुशलं जनसंसदि ।
यामा मनुगता मन्दं पित्रा प्रव्राजितं वनम् ॥ १०८
सीता सत्पथमास्थाय क नुसा वर्तते प्रिया ।
तया विहीनः कृपणः कथं लक्ष्मण ! धारये ॥ १०९
यामा मनुगता राज्या ह्रष्टं विगतचेतसम् ।
तच्चारुवेश्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम् ॥ ११०
अपश्यतो मुखं तस्या स्सीदतीव मनो मम ।
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् ॥ १११
वैदेह्या वाक्य मतुलं कदा श्रोष्यामि लक्ष्मण ! ।
प्राप्य दुःखं वने श्यामा सामां मन्मथकर्शितम् ॥ ११२
नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ।
किंनु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ! ॥ ११३
'कसा स्नु 'षेति पृच्छन्तीं कथं चाति मनस्विनीम् ।
गच्छ लक्ष्मण ! पश्य त्वं भरतं भ्रातृवत्सलम् ॥ ११४
नह्यहं जीवितुं शक्तस्ता मृते जनकात्मजाम् ।"
इति रामं महात्मानं विलपन्त मनाथवत् ॥ ११५
उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ।
"संस्तम्भ ! राम ! भद्रं ते माशुचः पुरुषोत्तम ! ॥ ११६
नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ।
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने ॥ ११७
अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते ।
यदि गच्छति पाताळं ततोह्यधिकमेववा ॥ ११८

सर्वथा रावणस्याव न्नभविष्यति राघव ! ।
प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः ॥ ११९

ततोहास्यति वा सीतां निधनं वा गमिष्यति ।
यदि यात्यदिते गर्भं रावण स्सह सीतया ॥ १२०

तत्राप्येनं हनिष्यामि नचेद्धास्यति मैथिलीम् । दृ
स्वास्थ्यं भद्रं भजस्वार्य ! त्यज्यतां कृपणामतिः ॥ १२१

अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते ।
उत्साहो बलवा नार्य ! नास्त्युत्साहात्परं बलम् ॥ १२२

सोत्साहस्यास्ति लोकेऽस्मिन् नकिञ्चिदपिदुर्लभम् ।
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ॥ १२३

उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि ।
त्यज्यतां कामवृत्तत्वं शोकं सन्नम्य पृष्ठतः ॥ १२४

महात्मानं कृतात्मान मात्मानं नावबुद्ध्यसे ।"
एवं सम्बोधित स्तत्र शोकोपहतचेतनः ॥ १२५

न्यस्य शोकञ्च मोहञ्च ततो धैर्यमुपागमत् ।
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ॥ १२६

रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम् ।
निरीक्षमाण स्सहसा महात्मा सर्वं वनं निर्झरकन्दरांश्च ।
उद्विग्नचेता स्सहलक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ १२७

तं मत्तमातङ्गविलासगामी गच्छन्त मव्यग्रमना महात्मा ।
स लक्ष्मणो राघव मप्रमत्तो ररक्ष धर्मेण बलेनचैव ॥ १२८

तादृश्यमूकस्य समीपचारी चरन्ददर्शाद्भुतदर्शनीयौ ।
शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित् ॥ १२९
सतौ महात्मा गजमन्दगामी शाखामृग स्तत्रचिरं चरन्तौ ।
दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः ॥ १३०
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ।
त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु र्महौजसौ राघवलक्ष्मणौ तौ ॥ १३१

इति श्रीमत्किष्किन्धाकाण्डे प्रथमस्सर्गः ॥

॥ द्वितीयस्सर्गः ॥

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।
वरायुधधरौ वीरौ सुग्रीव श्शङ्कितोऽभवत् ॥ १
उद्विग्न हृदयस्सर्वा दिशस्समवलोकयन् ।
न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ॥ २
नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ ।
कपेः परमभीतस्य चित्तं व्यबससाद ह ॥ ३
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ।
सुग्रीवः परमोद्विग्नः सर्वैरनुचरै स्सह ॥ ४
ततस्स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ ५
"एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।
छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥ ६

ततस्सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।
जग्मुर्गिरितटात्तस्मा दन्यच्छिखर मुत्तमम् ॥ ७
ते क्षिप्र मधिगम्याथ यूथपा यूथपर्षभम् ।
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥ ८
एक मेकायन गताः प्लवमाना गिरेर्गिरिम् ।
प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ॥ ९
तत इशाखामृगा स्सर्वे प्लवमाना महाबलाः ।
वभञ्जु श्च नगां स्तत्र पुष्पिता न्दुर्गसंश्रितान् ॥ १०
आप्लवन्तो हरिवरा स्सर्वत स्तं महागिरिम् ।
मृगमार्जारशार्दूलां स्त्रासयन्तो ययु स्तदा ॥ ११
तत स्सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ।
सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलय स्थिताः ॥ १२
तत स्तं भयसंविग्नं वालिकिल्विषशङ्कितम् ।
उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ १३
" संभ्रम स्त्यज्यता मेष सर्वै र्वालिकृते महान् ।
मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ १४
यस्मा दुद्विग्नचेता स्त्वं प्रद्रुतो हरिपुङ्गव ! ।
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ १५
यस्मा त्तव भयं सौम्य ! पूर्वकात्पापकर्मणः ।
स नेह वाली दुष्टात्मा नते पश्याम्यहं भयम् ॥ १६
अहो शाखामृगत्वं ते व्यक्त मेव प्लवङ्गम ! ।
लघुचित्ततयाऽत्मानं न स्थापयसि यो मतौ ॥ १७

बुद्धिविज्ञानसंपन्न इङ्गितै स्सर्व माचर ।
न ह्यबुद्धि गतो राजा सर्वभूतानि शास्ति हि ॥" १८
सुग्रीव स्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।
तत श्शुभतरं वाक्यं हनूमन्त मुवाचह ॥ १९
" दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।
कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ २०
वालि प्रणिहिता वेतौ शङ्केऽहं पुरुषोत्तमौ ।
राजानो बहुमित्रा श्च विश्वासो नात्र हि क्षमः ॥ २१
अरय श्च मनुष्येण विज्ञेया श्छन्नचारिणः ।
विश्वस्ताना मविश्वस्ता रन्ध्रेषु प्रहरन्ति हि ॥ २२
कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ।
भवन्ति परहन्तार स्ते ज्ञेयाः प्राकृतै र्नरैः ॥ २३
तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम ! ।
इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥ २४
लक्षयस्व तयो र्भावं प्रहृष्टमनसौ यदि ।
विश्वासयन्प्रशंसाभि रिङ्गितैश्च पुनःपुनः ॥ २५
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव ! ।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २६
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम ! ।
व्याभाषितै र्वा विज्ञेया स्या दुष्टादुष्टता तयोः ॥" २७
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ।
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ २८

'त'थेति सम्पूज्य वच स्तु तस्य तत्कपे स्सुग्रीवस्य दुरासदस्य च ।
महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥

इति श्रीमत्किष्किन्धाकाण्डे द्वितीयस्सर्गः ॥

॥ तृतीयस्सर्गः ॥

वचो विज्ञाय हनुमां स्सुग्रीवस्य महात्मनः ।
पर्वता दृश्यमूका त्तु पुप्लुवे यत्र राघवौ ॥ १

कपिरूपं परित्यज्य हनूमा न्मारुतात्मजः ।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ २

तत स्स हनुमा न्वाचा श्लक्ष्णया सुमनोज्ञया ।
विनीतवदुपागम्य राघवौ प्रणिपत्यच ॥ ३

आबभाषे तदा वीरौ यथावत्प्रशशंस च ।
संपूज्यविधिव द्वीरो हनूमान्मारुतात्मजः ॥ ४

उवाच कामतो वाक्यं मृदुसत्यपराक्रमौ ।
"राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ॥ ५

देशं कथ मिमं प्राप्तौ भवन्तौ वरवर्णिनौ ।
त्रासयन्तौ मृगगणानन्यां श्च वनचारिणः ॥ ६

पम्पातीररुहान्वृक्षा न्वीक्षमाणौ समन्ततः ।
इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ ॥ ७

धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ।
निःश्वसन्तौ वरभुजौ पीडयन्ता विमाः प्रजाः ॥ ८

सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ।
शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ ९
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ।
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ १०
प्रभया पर्वतेन्द्रोऽयं युवयो रवभासितः ।
राज्यार्हावमरप्रख्यौ कथं देश मिहागतौ ॥ ११
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥ १२
यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुन्धराम् ।
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ १३
सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ ।
आयता श्च सुवृत्ता श्च बाहवःपरिघोपमाः ॥ १४
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ।
उभौ योग्या वहं मन्ये रक्षितुं पृथिवी मिमाम् ॥ १५
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ।
इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने ॥ १६
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ।
सम्पूर्णा निशितैर्बाणैस्तूणा श्च शुभदर्शनाः ॥ १७
जीवितान्तकरैर्घोरैरश्वसद्भि रिव पन्नगैः ।
महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ ॥ १८
खड्गा वेतौ विराजेते निर्मुक्ता विव पन्नगौ ।
एवं मां परिभाषन्तं कस्मा द्वै नाभिभाषथः ॥ १९

सुग्रीवो नाम धर्मात्मा काश्चि द्वानरयूथपः ।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ २०
प्राप्तोऽहं प्रेषित स्तेन सुग्रीवेण महात्मना ।
राज्ञा वानरमुख्यानां हनूमा न्नाम वानरः ॥ २१
युवाभ्यां सहधर्मात्मा सुग्रीव स्सख्य मिच्छति ।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ २२
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।
ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥" २३
एव मुक्ता तु हनुमां स्तौ वीरौ रामलक्ष्मणौ ।
वाक्यज्ञौ वाक्यकुशलः पुन र्नोवाच किंचन ॥ २४
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मण मब्रवीत् ।
प्रहृष्टवदन श्श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ २५
"सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।
तमेव काङ्क्षमाणस्य ममान्तिक मुपागतः ॥ २६
तमभ्यभाष सौमित्रे ! सुग्रीवसचिवं कपिम् ।
वाक्यज्ञं मधुरै र्वाक्यै स्स्नेहयुक्त मरिन्दम ! ॥ २७
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः ।
नासामवेदविदुष श्शक्य मेवं प्रभाषितुम् ॥ २८
नूनं व्याकरणं कृत्स्न मनेन बहुधा श्रुतम् ।
बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ २९
न मुखे नेत्रयो र्वापि ललाटे च भ्रुवो स्तथा ।
अन्येष्वपि च गात्रेषु दोष स्संविदितः क्वचित् ॥ ३०

अविस्तर मसंदिग्ध मविलम्बित मद्रुतम् ।
उरस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे ॥ ३१
संस्कारक्रमसम्पन्ना मद्रुता मविलम्बिताम् ।
उच्चारयति कल्याणीं वाचं हृदयहारिणीम् ॥ ३२
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।
कस्य नाराध्यते चित्त मुद्यतासेररेरपि ॥ ३३
एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु ।
सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ! ॥ ३४
एवं गुणगणै र्युक्ता यस्य स्युः कार्यसाधकाः ।
तस्य सिद्ध्यन्ति सर्वार्था दूतवाक्यप्रचोदिताः" ३५
एव मुक्तस्तु सौमित्रि स्सुग्रीवसचिवं कपिम् ।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ ३६
विदिता नौ गुणा विद्वं ! त्सुग्रीवस्य महात्मनः ।
तमेव चाऽवां मार्गाव स्सुग्रीवं प्लवगेश्वरम् ॥ ३७
यथा त्रवीषि हनुमं ! त्सुग्रीववचना दिह ।
तत्तथा हि करिष्यावो वचनात्तव सत्तम !" ॥ ३८
तत्तस्य वाक्यं निपुणं निशम्य प्रकृष्टरूपः पवनात्मजः कपिः ।
मन स्समाधाय जयोपपत्तौ सख्यं तदा कर्तु मियेष ताभ्याम् ॥ ३९

इति श्रीमत्किष्किन्धाकाण्डे तृतीयस्सर्गः ॥

॥ चतुर्थस्सर्गः ॥

ततः प्रहृष्टो हनुमा न्कृत्यवा नीति तद्वचः ।
श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ॥ १

"भव्यो राज्यागम स्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवा न्प्राप्तः कृत्यं चैत दुपागतम् ॥ २
ततः परमसंहृष्टो हनूमान् प्लवगर्षभः ।
प्रत्युवाच ततो वाक्यं रामंवाक्यविशारदः ॥ ३
"किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
आगतस्सानुजो दुर्गं नानाव्याळमृगायुतम् ॥" ४
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५
"राजादशरथो नाम द्युतिमान्धर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ ६
न द्वेष्टा विद्यते तस्य नच स द्वेष्टि कञ्चन ।
सच सर्वेषु भूतेषु पितामह इवापरः ॥ ७
अग्निष्टोमादिभि र्यज्ञै रिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनै श्श्रुतः ॥ ८
शरण्य स्सर्वभूतानां पितु र्निर्देशपारगः ।
वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ॥ ९
राजलक्षणसम्पन्न स्सरक्तो राजसम्पदा ।
राज्या द्भ्रष्टो वने वस्तुं मया सार्धं मिहागतः ॥ १०
भार्यया च महातेजा स्सीतयाऽनुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ११
अहमस्यावरो भ्राता गुणैर्दास्य मुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ १२

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्यच ॥ १३
रक्षसाऽपहृता भार्या रहिते कामरूपिणा ।
तच्चन ज्ञायते रक्षःपत्नी येनास्य सा हृता ॥ १४
दनुर्नाम दितेः पुत्रश्शापाद्राक्षसतां गतः ।
आख्यात स्तेन सुग्रीव स्समर्थो वानरर्षभः ॥ १५
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एव मुक्त्वा दनु स्स्वर्गं भ्राजमानो गतस्सुखम् ॥ १६
एत ते सर्व माख्यातं याथातथ्येन पृच्छतः ।
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ १७
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथ मिच्छति ॥ १८
पिता यस्य पुराद्यासी च्छरण्यो धर्मवत्सलः ।
तस्य पुत्र इशरण्य श्च सुग्रीवं शरणं गतः ॥ १९
सर्वलोकस्य धर्मात्मा शरण्य इशरणं पुरा ।
गुरु र्मे राघव स्सोऽयं सुग्रीवं शरणं गतः ॥ २०
यस्य प्रसादे सततं प्रसीदेयु रिमाःप्रजाः ।
स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते ॥ २१
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानिता स्सततं राज्ञा सदा दशरथेनवै ॥ २२
तस्यायं पूर्वजः पुत्र स्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु राम इशरण मागतः ॥ २३

शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः ॥" २४
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् ।
हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २५
"ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्यादर्शन मागताः ॥ २६
स हि राज्या त्परिभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ २७
करिष्यति स साहाय्यं युवयो र्भास्करात्मजः ।
सुग्रीव स्सह चास्माभि स्सीतायाः परिमार्गणे ॥" २८
इत्येव मुक्तो हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे सोऽभिगच्छेम सुग्रीव' मिति राघवम् ॥ २९
एवं ब्रुवाणं धर्मात्मा हनुमन्तं सलक्ष्मणः ।
प्रतिपूज्य यथान्याय मिदं प्रोवाच राघवम् ॥ ३०
"कपिः कथयते ह्येष यथाऽयं मारुतात्मजः ।
कृत्यवां स्त्वोऽपि संप्राप्तः कृतकृत्योऽसि राघव ! ॥ ३१
प्रसन्नमुखवर्ण श्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनुमान्मारुतात्मजः ॥" ३२
तत स्सतु महाप्राज्ञो हनुमा न्मारुतात्मजः ।
जगामाऽदाय तौ वीरौ हरिराजाय राघवौ ॥ ३३
भिक्षुरूपं परित्यज्य वानरं रूप माश्रितः ।
पृष्ठ मारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३४

स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।
गिरिवर मुरुविक्रमः प्रयात स्स शुभमति स्सह रामलक्ष्मणाभ्यां ॥

इति श्रीमात्किष्किन्धाकाण्डे चतुर्थस्सर्गः ॥

॥ पञ्चमस्सर्गः ॥

ऋश्यमूकात्तु हनुमान्गत्वा तु मलयं गिरिम् ।
आचचक्षे तदावीरौ कपिराजाय राघवौ ॥ १

"अयं रामो महाप्राज्ञ स्संप्राप्तो दृढविक्रमः ।
लक्ष्मणेन सहभ्रात्रा रामोऽयं सत्यविक्रमः ॥ २

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।
धर्मे निगदित श्चैव पितु र्निर्देशपारगः ॥ ३

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वां शरण मागतः ॥ ४

राजसूयाश्वमेधै श्च वह्निर्येनाभितर्पितः ।
दक्षिणाश्च तथोत्सृष्टा गाव श्शतसहस्रशः ॥ ५

तपसा सत्यवाक्येन वसुधा येन पालिता ।
स्त्रीहेतो स्तस्य पुत्रोऽयं राम स्त्वां शरणं गतः ॥ ६

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।
प्रतिगृह्यार्चयस्वैतौ पूजनीयतमा वुभौ ॥ ७

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।
भयं च राघवाद्घोरं प्रजहौ विगतज्वरः ॥ ८

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः ।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९
भवान्धर्मविनीत श्च विक्रान्त स्सर्ववत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ १०
तन्ममैवैष सत्कारो लाभ श्चै वोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ ११
रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।
गृह्यतां पाणिना पाणि र्मर्यादा बध्यतां ध्रुवा ॥" १२
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
स प्रहृष्टमनाहस्तं पीडयामास पाणिना ॥ १३
हृद्यं सौहृद मालम्ब्य पर्यष्वजत पीडितम् ।
ततो हनूमां त्सन्त्यज्य भिक्षुरूपमरिन्दमः ॥ १४
काष्ठयो स्स्वेन रूपेण जनयामास पावकम् ।
दीप्यमानं ततो वह्निं पुष्पै रभ्यर्च्य सत्कृतम् ॥ १५
तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः ।
ततोऽग्निं दीप्यमानं तौ चक्रतु श्च प्रदक्षिणम् ॥ १६
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ।
तत स्सुप्रीतमनसौ तावुभौ हरिराघवौ ॥ १७
अन्योन्य मभिवीक्षन्तौ नरेन्द्रि मुपजग्मतुः ।
"त्वं वयस्योऽसि मे ह्यको ह्येकं दुःखं सुखं वनौ ॥" १८
सुग्रीवो राघवं वाक्य मित्युवाच प्रहृष्टवत् ।
ततस्स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् ॥ १९

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।
लक्ष्मणायाथ संहृष्टो हनूमान् प्लवगर्षभः ॥ २०
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।
ततः प्रहृष्ट स्सुग्रीवः श्लक्ष्णं मधुरया गिरा ॥ २१
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।
"अहं विनिकृतो राम! चरामीह भयार्दितः ॥ २२
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ।
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः ॥ २३
वालिना निकृतो भ्रात्रा कृतवैर श्च राघव! ।
वालिनो मे महाभाग! भयार्तस्याभयं कुरु ॥ २४
कर्तु मर्हसि काकुत्स्थ! भयं मे न भवे द्यथा ।"
एव मुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ॥ २५
प्रत्यभाषत काकुत्स्थ स्सुग्रीवं प्रहसन्निव ।
"उपकारफलं मित्रं विदितं मे महाकपे! ॥ २६
वालिनं तं वधिष्यामि तव भार्यापहारिणम् ।
अमोघा स्सूर्यसङ्काशा ममैते निशिता इशराः ॥ २७
तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ २८
तीक्ष्णाग्रा ऋजुपर्वाण स्सरोषा भुजगा इव ।
तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः ॥ २९
शरै र्विनिहतं भूमौ विकीर्ण मिव पर्वतम् ।"
स तु तद्वचनं श्रुत्वा राघवस्यात्मनोहितम् ॥ ३०

सुग्रीवः परमप्रीत स्सुमहद्वाक्य मब्रवीत् ।
तव प्रसादेन नृसिंह ! राघव ! प्रियां च राज्यं च समाप्नुया महम् ।
तथा कुरु त्वं नरदेव ! वैरिणं यथा निहंस्याशु रिपुं ममाग्रजम् ॥"
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ३२

इति श्रीमत्किष्किन्धाकाण्डे पञ्चमस्सर्गः ॥

॥ षष्ठस्सर्गः ॥

पुनरेवाब्रवी त्प्रीतो राघवं रघुनन्दनम् ।
"अय माख्याति मे राम ! सचिवो मन्त्रिसत्तमः ॥ १
हनूमान्यन्निमित्तं त्वं निर्जनं वन मागतः ।
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥ २
रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ।
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥ ३
अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ।
भार्याविरोगजं दुःख मचिरा त्त्वं विमोक्ष्यसे॥ ४
अहं ता मानयिष्यामि नष्टां वेदश्रुती मिव ।
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्स्थले ॥ ५
अह मानीय दास्यामि तव भार्यां मरिन्दम ! ।
इदं तथ्यं मम वच स्त्व मवेहि च राघव ! ॥ ६
न शक्या सा जयितु मपि सेन्द्रै स्सुरासुरैः ।
तव भार्या महाबाहो ! भक्ष्यं विषकृतं यथा ॥ ७

त्यजशोकं महाबाहो! तां कान्तामानयामि ते ।
अनुमाना तु जानामि मैथिली सा न संशयः ॥ ८
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।
क्रोशन्ती 'राम रा'मेति' 'लक्ष्मणेति'च विस्वरम् ॥ ९
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधू र्यथा ।
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ॥ १०
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ।
तान्यस्माभि र्गृहीतानि निहितानि च राघव! ॥ ११
आनयिष्याम्यहं तानि प्रत्यभिज्ञातु मर्हसि ।"
तमब्रवीत्ततो राम स्सुग्रीवं प्रियवादिनम् ॥ १२
"आनयस्व सखे! शीघ्रं किमर्थं प्रविलम्बसे ।"
एव मुक्तस्तु सुग्रीव श्शैलस्य गहनां गुहाम् ॥ १३
प्रविवेश तत श्शीघ्रं राघवप्रियकाम्यया ।
उत्तरीयं गृहीत्वातु शुभान्याभरणानिच ॥ १४
'इदं प' श्येति रामाय दर्शयामास वानरः ।
ततो गृहीत्वा तद्वास श्शुभान्याभरणानि च ॥ १५
अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ।
सीतास्नेहप्रवृत्तेन सतु बाष्पेणदूषितः ॥ १६
'हाप्रि'येति रुदन्धैर्य मुत्सृज्य न्यपतत्क्षितौ ।
हृदि कृत्वातु बहुशस्तमलंकार मुत्तमम् ॥ १७
निश्श्वास भृशं सर्पो बिलस्थ इव रोषितः ।
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ॥ १८

परिदेवयितुं दीनंराम स्समुपचक्रमे ।
"पश्य लक्ष्मण! वैदेह्या संत्यक्तं ह्रियमाणया ॥ १९
उत्तरीय मिदं भूमौ शरीरा द्भूषणानि च ।
शाद्वलिन्यां ध्रुवं भूमौ सीतया ह्रियमाणया ॥ २०
उत्सृष्टं भूषण मिदं तथारूपं हि दृश्यते ।"
एव मुक्तस्तु रामेण लक्ष्मणो वाक्य मब्रवीत् ॥ २१
नाहंजानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥" २२
तत स्स राघवो दीन स्सुग्रीव मिद मब्रवीत् ।
"ब्रूहिसुग्रीव! कं देशं ह्रियन्ती लक्षिता त्वया ॥ २३
रक्षसा रौद्ररूपेण मम प्राणै/ प्रियाप्रिये । हृता ।
कवा वसति तद्रक्षो महद्व्यसनदं मम ॥ २४
यन्निमित्त महं सर्वान्नाशयिष्यामि राक्षसान् ।
हरता मैथिलीं येन मांच रोषयताभृशम् ॥ २५
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ।
मम दयिततरा हृता वनान्ता द्रजनिचरेण विमथ्य येन सा ।
कथय मम रिपुं त्व मद्य वै प्लवगपते! यमसादनं नयामि ॥" २६

इति श्रीमत्किष्किन्धाकाण्डे पञ्चस्सर्गः ॥

॥ सप्तमस्सर्गः ॥

एव मुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।
अब्रवी त्प्राञ्जलि र्वाक्यं सबाष्पं बाष्पगद्गदः ॥ १

"न जाने निलयं तस्य सर्वथा पापरक्षसः ।
सामर्थ्यं विक्रमं वापिदौष्कुले यस्य वाकुलम् ।। २
सत्यं ते प्रतिजानामि त्यज शोकं मरिन्दम ! ।।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ।। ३
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।
तथाऽस्मि कर्ता नचिरा त्तथाप्रीतो भविष्यसि ।। ४
अलं वैक्लव्य मालम्ब्य धैर्यं मात्मगतं स्मर ।
त्वद्विधाना मसदृश मीदृशं विद्धि लाघवम् ।। ५
मयाऽपि व्यसनं प्राप्तं भार्याहरणजं महत् ।
न चाह मेवं शोचामि नचधैर्यंपरित्यजे ।। ६
नाहं ता मनुशोचामि प्राकृतो वानरोऽपि सन् ।
महात्मा च विनीतश्च किंपुन र्धृतिमान्भवान् ।। ७
बाष्प मापतितं धैर्यान्नि ग्रहीतुं त्वमर्हसि ।
मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टु मर्हसि ।। ८
व्यसने वाऽर्थकृच्छ्रेवा भयेवा जीवितान्तके ।
विमृशन्बै स्वयाबुद्ध्या धृतिमान्नावसीदति ।। ९
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
समज्जत्यवशःशोके भाराक्रान्तेव नौर्जले ।। १०
एषोऽञ्जलि र्मया बद्धः प्रणयात्त्वां प्रसादये ।
पौरुषं श्रयशोकस्य नान्तरं दातु मर्हसि ।। ११
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ।
तेज श्च क्षीयते तेषां नत्वं शोचितु मर्हसि ।। १२

शोकेनाभिप्रपन्नस्य जीविते चापि संशयः ।
स शोकं त्यज राजेन्द्र! धैर्यमाश्रयकेवलम् ॥ १३
हितं वयस्यभावेन ब्रूमि नोपदिशामिते ।
वयस्यतां पूजयन्मेन त्वं शोचितु मर्हसि ॥" १४
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।
मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ १५
प्रकृतिस्थस्तु काकुत्स्थ स्सुग्रीव वचनात्प्रभुः ।
सम्परिष्वज्य सुग्रीव मिदं वचनमब्रवीत् ॥ १६
"कर्तव्यं यद्वयस्येन स्निग्धेनच हितेनच ।
अनुरूपंच युक्तंच कृतं सुग्रीव! तत्त्वया ॥ १७
एष च प्रकृतिस्थोऽह मनुनीतस्त्वया सखे! ।
दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ॥ १८
किंतु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९
मयाच यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।
वर्षास्विवच सुक्षेत्रे सर्वं सम्पद्यते त्वयि ॥ तव ॥ २०
मयाच यदिदं वाक्यमभिमानात्समीरितम् ।
तत्त्वया हरिशार्दूल! तत्त्वमित्युपधार्यताम् ॥ २१
अनृतं नोक्तपूर्वं मे नचवक्ष्ये कदाचन ।
एतत्ते प्रतिजानामि सत्येनैवच ते शपे ॥" २२
ततः प्रहृष्ट स्सुग्रीवो वानरै स्सचिवैस्सह ।
राघवस्य वचश्श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३

एव मेकान्त सम्पृक्तौ ततस्तौ नरवानरौ ।
उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ॥ २४
महानुभावस्य वचो निशम्य हरिर्नराणा मृषभस्य तस्य ।
कृतं समेने हरिवीरमुख्य स्तदा स्वकार्यं हृदयेन विद्वान् ॥ २५

इति श्रीमत्किष्किन्धाकाण्डे सप्तमस्सर्गः ॥

॥ अष्टमस्सर्गः ॥

परितुष्ट स्तु सुग्रीवस्तेन वाक्येन वानरः ।
लक्ष्मणस्याग्रतो राम मिदं वचनमब्रवीत् ॥ १
"सर्वथाऽह मनुग्राह्यो देवताना मसंशयः ।
उपपन्नगुणोपेत स्सखा यस्य भवान्मम ॥ २
शक्यं खलु भवेद्राम! सहायेन त्वयाऽनघ! ।
सुरराज्य मपि प्राप्तुं स्वराज्यं किंपुनः प्रभो! ॥ ३
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव! ।
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ ४
अह मप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।
नतु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् ॥ ५
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् ।
निश्चला भवतिप्रीतिर्धैर्यं मात्मवता मिव ॥ ६
रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च ।
अविभक्तानि साधूना मवगच्छन्ति साधवः ॥ ७

आढ्यो वापि दरिद्रो वा दुःखित स्सुखितोऽपिवा ।
निर्दोषोवा सदोषोवा वयस्यः परमा गतिः ॥ ८
धनत्यागस्सुखत्यागो देहत्यागोऽपिवा पुनः ।
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ९
'तत्तथे' त्यब्रवीद्राम स्सुग्रीवं प्रियवादिनम् ।
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १०
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।
सुग्रीव स्सर्वतश्चक्षु र्वने लोल मपातयत् ॥ ११
स ददर्श ततस्साल मविदूरे हरीश्वरः ।
सुपुष्प मिषत्पत्राढ्यं भ्रमरै रुपशोभितम् ॥ १२
तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ।
सालस्यास्तीर्य सुग्रीवो निषसाद स राघवः ॥ १३
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ।
सालशाखां समुत्पाट्य विनीत मुपवेशयत् ॥ १४
सुखोपविष्टं रामं तु प्रसन्न मुदधिं यथा ।
फलपुष्पसमाकीर्णे तस्मिन्गिरिवरोत्तमे ॥ १५
ततः प्रहृष्टस्सुग्रीवः श्लक्ष्णं मधुरया गिरा ।
उवाच प्रणया द्रामं हर्षव्याकुलिताक्षरम् ॥ १६
"अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।
ऋश्यमूकं गिरिवरं हृतभार्य स्सुदुःखितः ॥ १७
सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः ।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ! ॥ १८

वालिनो मे भयार्तस्य सर्वलोकाभयंकर! ।
ममापि त्व मनाथस्य प्रसादं कर्तुमर्हसि ॥" १९
एव मुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।
प्रत्युवाच स काकुत्स्थ स्सुग्रीवं प्रहसन्निव ॥ २०
"उपकारफलं मित्र मपकारोऽरिलक्षणम् ।
अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ २१
इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः ।
कार्तिकेयवनोद्भूता इशराहेमविभूषिताः ॥ २२
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ।
सुपर्वाणस्सुतीक्ष्णाग्रा स्सरोषा भुजगा इव ॥ २३
भ्रातृसंज्ञ ममित्रं ते वालिनं कृतकिल्बिषम् ।
शरै र्विनिहतं पश्य विकीर्ण मिव पर्वतम् ॥" २४
राघवस्य वच श्श्रुत्वा सुग्रीवो वाहिनीपतिः ।
प्रहर्ष मतुलं लेभे 'साधुसा' ध्विति चाब्रवीत् ॥ २५
"राम! शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ।
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ २६
स्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् ।
कृतः प्राणै र्बहुमत स्सत्येनापि शपामि ते ॥ २७
वयस्य इति कृत्वाच विस्रब्धं प्रवदाम्यहम् ।
दुःख मन्तर्गतं यन्मे मनो हरति नित्यशः ॥" २८
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।
बाष्पोपहतया वाचा नोच्चैश्शक्नोतिभाषितुम् ॥ २९

बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।
धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ ३०
संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।
विनिश्वस्यच तेजस्वी राघवं वाक्य मब्रवीत् ॥ ३१
"पुराऽहं वालिना राम! राज्या त्स्वादवरोपितः ।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ३२
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी ।
सुहृद श्च मदीया ये संयता बन्धनेषु ते ॥ ३३
यत्नवां श्च सुदुष्टात्मा मद्विनाशाय राघव ! ।
बहुश स्तत्प्रयुक्ता श्च वानरा निहता मया ॥ ३४
शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव ! ।
नोपसर्पाम्यहं भीतो 'भये सर्वेहि बिभ्यति' ॥ ३५
केवलंहि सहाया मे हनुमत्प्रमुखास्त्विमे ।
अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥ ३६
एते हि कपय स्तिग्धा मां रक्षन्ति समन्ततः ।
सहगच्छन्तिगन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ३७
संक्षेप स्त्वेष मे राम! किमुक्त्वाविस्तरं हि ते ।
स मे ज्येष्ठो रिपु र्भ्राता वाली विश्रुतपौरुषः ॥ ३८
तद्विनाशाद्धिमे दुःखं प्रणष्टं स्या दनन्तरम् ।
सुखंमे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ३९
एष मे राम! शोकान्त इशोकार्तेन निवेदितः ।
दुःखित स्सुखितो वापि सख्युर्नित्यं सखा गतिः ॥" ४०

श्रुत्वैतद्वचनं रामस्सुग्रीव मिद मब्रवीत् ।
"किंनिमित्त मभू द्वैरं श्रोतु मिच्छामि तत्त्वतः ॥ ४१
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ! ।
आनन्तर्यं विधास्यामि संप्रधार्य बलाबलं ॥ ४२
बलवान् हिममामर्ष श्शुत्वात्वामवमानितम् ।
वर्तते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४३
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।
सृष्ट श्च हि मया बाणो निरस्त श्च रिपु स्तव ॥" ४४
एव मुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ।
प्रहर्ष मतुलं लेभे चतुर्भि स्सह वानरैः ॥ ४५
ततः प्रहृष्टवदन स्सुग्रीवो लक्ष्मणाग्रजे ।
वैरस्य कारणं तत्त्व माख्यातु मुपचक्रमे ॥ ४६

इति श्रीमत्किष्किन्धाकाण्डे अष्टमस्सर्गः ॥

॥ नवमस्सर्गः ॥

[श्रूयतां राम ! यद्वृत्त मादितः प्रभृति त्वया ।
यथा वैरं समुद्भूतं यथा चाहं निराकृतः ॥] १
"वाली नाम मम भ्राता ज्येष्ठ श्शत्रुनिषूदनः ।
पितु र्बहुमतो नित्यं ममापि च तथा पुरा ॥ २
पितर्युपरतेऽस्माकं ज्येष्ठोऽय मिति मन्त्रिभिः ।
कपीना मीश्वरो राज्ये कृतः परमसम्मतः ॥ ३

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥ ४
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।
तेन तस्य मह द्वैरं स्त्रीकृतं विश्रुतं पुरा ॥ ५
स तु सुप्तजने रात्रौ किष्किन्धाद्वार मागतः ।
नर्दतिस्म सुसंरब्धो वालिनं चाह्वय द्रणे ॥ ६
प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ७
स तु वै निस्सृतः क्रोधात्तं हन्तु मसुरोत्तमम् ।
वार्यमाणस्तत स्त्रीभिर्मयाच प्रणतात्मना ॥ ८
सतु निर्धूय सर्वान्नो निर्जगाम महाबलः ।
ततोऽह मपि सौहार्दा न्निस्सृतो वालिना सह ॥ ९
सतु मे भ्रातरं दृष्ट्वा मांचदूरा दवस्थितम् ।
असुरो जातसंत्रासः प्रदुद्राव ततोभृशम् ॥ १०
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ ।
प्रकाश श्च कृतो मार्ग श्चन्द्रेणोद्गच्छतातदा ॥ ११
स तृणै रावृतं दुर्गं धरण्या विवरं महत् ।
प्रविवेशासुरोवेगा दावा मासाद्य विष्ठितौ ॥ १२
तं प्रविष्टं रिपुं दृष्ट्वा विलं रोषवशं गतः ।
मा मुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १३
'इह त्वंतिष्ठ सुग्रीव ! विलद्वारि समाहितः ।
यावत्तत्र प्रविश्याहं निहन्मि सहसारिपुम् ॥' १४

मया त्वेत द्वच श्रुत्वा याचित स्स परन्तपः ।
शापयित्वातु मां पद्भ्यां प्रविवेश बिलं महत् ॥ १५
तस्य प्रविष्टस्य बिलं साग्रस्संवत्सरो गतः ।
स्थितस्यच मम द्वारि स कालो व्यत्यवर्तत ॥ १६
अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।
भ्रातरं न च पश्यामि पापाशङ्कीच मे मनः ॥ १७
अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् ।
सफेनं रुधिरं रक्त महं दृष्ट्वा सुदुःखितः ॥ १८
नर्दतामसुराणां च ध्वनि र्मेश्रोत्र मागतः ।
निर्हतस्यच सङ्ग्रामे क्रोशतो मित्स्वनो गुरोः ॥ १९
अहंत्ववगतो बुद्ध्या चिह्नै स्तै र्भ्रातरं हतम् ।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥ २०
शोकार्त श्चोदकं कृत्वा किष्किधा मागत स्सखे ! ।
गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभि श्श्रुतम् ॥ २१
ततोऽहंतै स्समागम्य सम्मतै रभिषेचितः ।
राज्यं प्रशासत स्तस्य न्यायतोममराघव ! ! २२
आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ।
अभिषिक्तं तु मांदृष्ट्वा वाली संरक्तलोचनः ॥ २३
मदीया न्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ।
निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ! ॥ २४
न प्रावर्तत मे बुद्धि र्भ्रातु गौरवयन्त्रिता ।
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरंतदा ॥ २५

मानयं स्तं महात्मानं यथावच्चाभ्यवादयम् ।
उक्ताश्चनाशिष स्तेन सन्तुष्टेनान्तरात्मना ॥ २६
नत्वा पदावहं तस्य मकुटेनास्पृशं प्रभो !
अपि वाली मम क्रोधा न्नप्रसादं चकारसः ॥" २७

इति श्रीमत्किष्किन्धाकाण्डे नवमस्सर्गः ॥

॥ दशमस्सर्गः ॥

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ।
अहं प्रसादयांचक्रे भ्रातरं प्रियकाम्यया ॥ १
'दिष्ट्याऽसि कुशलीप्राप्तो निहतश्च त्वयारिपुः ।
अनाथस्य हि मे नाथस्त्व मेकोऽनाथनन्दनः ॥ २
इदं बहुशलाकं ते पूर्णचन्द्र मिवोदितम् ।
छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ३
आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप ! ।
दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ ४
शोकसंविग्न हृदयो भृशं व्याकुलितेन्द्रियः ।
अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा ॥ ५
तस्मादेशा दपाक्रम्य किष्किन्धां प्राविशं पुनः ।
विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ॥ ६
अभिषिक्तो न कामेन तन्मे त्वं क्षन्तु मर्हसि ।
त्वमेव राजा मानार्हं स्सदाचाहं यथापुरम् ॥ ७

राजभावे नियोगोऽयं मया त्वद्विरहात्कृतः ।
सामात्यपौरनगरं स्थितं निहतकण्टकम् ॥ ८
न्यासभूत मिदं राज्यं तव निर्यातयाम्यहम् ।
माचरोषं कृथा स्सौम्य! मयि शत्रुनिबर्हण! ॥ ९
याचेत्वां शिरसा राजन्! मया बद्धोऽय मञ्जलिः ।
बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ॥ १०
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ।'
स्निग्ध मेवं ब्रुवाणं मां सतु निर्भर्त्स्य वानरः ॥ ११
'धिक्त्वा 'मितिच मामुक्त्वा बहुतत्तदुवाचह ।
प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् ॥ १२
मा माह सुहृदां मध्ये वाक्यं परमगर्हितम् ।
"विदितं वो यथा रात्रौ मायावी स महासुरः ॥ १३
मां समाह्वयत क्रूरो युद्धकाङ्क्षी सुदुर्मतिः ।
तस्य तद्वचनं श्रुत्वा निस्सृतोऽहं नृपालयात् ॥ १४
अनुयातश्च मां तूर्णं मयं भ्राता सुदारुणः ।
सतु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ॥ १५
प्राद्रव द्भयसन्त्रस्तो वीक्ष्याऽत्रां तमनुद्रुतौ ।
अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥ १६
तं प्रविष्टं विदित्वातु सुघोरं सुमहद्बिलम् ।
अय मुक्तोऽथ मे भ्राता मयातु क्रूरदर्शनः ॥ १७
अहत्वा नास्ति मे शक्तिः प्रतिगन्तु मितः पुरीम् ।
बिलद्वारि प्रतीक्षस्त्वं यावदेनं निहन्म्यहम् ॥ १८

स्थितोऽय 'मिति मत्वातु प्रविष्टोऽहं दुरासदम् ।
तंच मे मार्गमाणस्य गतस्संवत्सरस्तदा ॥ १९
सतु दृष्टो मया शत्रुरनिर्वेदा द्भयावहः ।
निहतश्च मया तत्र सोऽसुरो बन्धुभिस्सह ॥ २०
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेन तद्बिलम् ।
पूर्णमासी दुराक्रामं स्तनतस्तस्य भूतले ॥ २१
सूदयित्वातु तं शत्रुं विक्रान्तं दुन्दुभे स्सुतम् ।
निष्क्राम न्नेव पश्यामि विलस्य पिहितं मुखम् ॥ २२
विक्रोशमानस्यतु मे 'सुग्री 'वेति पुनःपुनः ।
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ २३
पादप्रहारै स्तु मया बहुभि स्तद्विदारितम् ।
ततोऽहं तेन निःक्रम्य यथा पुरमुपागतः ॥ २४
अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽत्मनः ।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥' २५
एव मुक्त्वातु मां तत्र वल्मीकेन वानरः ।
निर्वासयामास तदा वाली विगतसाध्वसः ॥ २६
तेनाह मपविद्धश्च हृतदारश्च राघव ! ।
तद्भयाच्च मही कृत्स्ना क्रान्तेयं सवनार्णवा ॥ २७
ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ २८
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।
अनागसा मया प्राप्तं व्यसनं पश्य राघव ! ॥ २९

वालिनस्तु भयार्तस्य सर्वलोकाभयंकर! ।
कर्तुं महँसि मे वीर! प्रसादं तस्यनिग्रहात् ॥" ३०
एव मुक्त स्सतेजस्वी धर्मज्ञो धर्मसंहितम् ।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ ३१
"अमोघा स्सूर्यसङ्काशा ममैतेनिशिता इशराः ।
तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ ३२
यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।
ताव त्सजीवे त्पापात्मा वाली चारित्रदूषकः ॥ ३३
आत्मानुमाना त्पश्यामि मग्नं त्वां शोकसागरे ।
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥" ३४
तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।
सुग्रीवः परमप्रीत स्सुमह द्वाक्य मब्रवीत् ॥ ३५

इति श्रीमत्किष्किन्धाकाण्डे दशमस्सर्गः ॥

॥ एकादशस्सर्गः ॥

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।
सुग्रीवः पूजयांचक्रे राघवं प्रशशंसच ॥ १
"असंशयं प्रज्वलितै स्तीक्ष्णैर्मर्मातिगै इशरैः ।
त्वं दहेः कुपितो लोका न्युगान्त इव भास्करः ॥ २
वालिनः पौरुषं यत्त द्यच्च वीर्यं धृति श्च या! ।
तन्ममैकमना इशृत्वा विधत्स्व यदनन्तरम् ॥ ३

समुद्रा त्पश्चिमा त्पूर्वं दक्षिणा दपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ ४
अम्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।
ऊर्ध्वं मुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ ५
बहव स्सारवन्त श्च वनेषु विविधा द्रुमाः ।
वालिना तरसा भग्ना बलं प्रथयताऽत्मनः ॥ ६
महिषो दुन्दुभि र्नाम कैलासशिखरप्रभः ।
बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ७
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।
जगाम सुमहाकाय स्समुद्रं सरितां पतिम् ॥ ८
ऊर्मिमन्त मभिक्रम्य सागरं रत्नसञ्चयम् ।
'मह्यं युद्धं प्रय'च्छेति तमुवाच महार्णवम् ॥ ९
ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः ।
अब्रवी द्वचनं राज ! न्नसुरं कालचोदितम् ॥ १०
'समर्थो नास्ति ते दातुं युद्धं युद्धविशारद ! ।
श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ ११
शैलराजो महारण्ये तपस्विशरणं परम् ।
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १२
गुहाप्रस्रवणोपेतो बहुकन्दरनिर्झरः ।
स समर्थ स्तवप्रीति मतुलां कर्तु माहवे' ॥ १३
'तं भीत' इति विज्ञाय समुद्र मसुरोत्तमः ।
हिमवद्वन मागच्छ च्छर श्चापा दिव च्युतः ॥ १४

तत स्तस्यगिरे श्श्वेता गजेन्द्रविपुला श्शिलाः ।
चिक्षेप बहुधा भूमौ दुन्दुभि र्विननादच ॥ १५
तत श्श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।
हिमवा नब्रवी द्वाक्यं स्वएवशिखरे स्थितः ॥ १६
"क्लेष्टुमर्हसि मां न त्वं दुन्दुभे ! धर्मवत्सल ।
रणकर्मस्वकुशल स्तपस्विशरणं ह्यहम् "॥ १७
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।
उवाच दुन्दुभि र्वाक्यं रोषात्संरक्तलोचनः ॥ १८
" यदियुद्धेऽसमर्थ स्त्वं मद्भया द्वा निरुद्यमः ।
त माचक्ष्व प्रदद्या न्मे योऽद्ययुद्धं युयुत्सतः ॥" १९
हिमवा नब्रवी द्वाक्यं श्रुत्वा वाक्यविशारदः ।
अनुक्तपूर्वं धर्मात्मा क्रोधात्त मसुरोत्तमम् ॥ २०
" वालीनाम महाप्राज्ञ श्शक्रतुल्यपराक्रमः ।
अध्यास्ते वानर श्श्रीमा न्किष्किन्धा मतुलप्रभाम् ॥ २१
ससमर्थो महाप्राज्ञस्तव युद्धविशारदः ।
द्वन्द्वयुद्धं महद्दातुं नमुचे रिव वासवः ॥ २२
तं शीघ्र मभिगच्छ त्वं यदि युद्ध मिहेच्छसि ।
सहि दुर्धर्षणो नित्यं शूर स्समरकर्मणि ॥" २३
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्ट स्स दुन्दुभिः ।
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ २४
धारय न्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ।
प्रावृषीव महामेघ स्तोयपूर्णो नभस्थले ॥ २५

ततस्तु द्वारमागम्य किष्किन्धायाः महाबलः ।
ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥ २६
समीपस्थान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः ।
विषाणेनोल्लिखन्दर्पात्तद्द्वारं द्विरदो यथा ॥ २७
अन्तःपुरगतो वाली श्रुत्वा शब्दं ममर्षणः ।
निष्पपात सहस्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ २८
मितं व्यक्ताक्षरपदं तमुवाचाथदुन्दुभिम् ।
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ २९
"किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि ।
दुन्दुभे! विदितो मेऽसि रक्ष प्राणान्महाबल! ॥ ३०
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।
उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ ३१
"न त्वं स्त्रीसन्निधौ वीर! वचनं वक्तुमर्हसि ।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३२
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।
गृह्यतां मुदयस्त्वैरं कामभोगेषु वानर! ॥ ३३
दीयतां सम्प्रदानंच परिष्वज्य च वानरान् ।
सर्वशाखामृगेन्द्र त्वं संपादय सुहृज्जनान् ॥ ३४
सुहृष्टां कुरु किष्किन्धां कुरुष्वात्मसमंपुरे ।
क्रीडस्वच सहस्त्रीभिरहंते दर्पनाशनः ॥ ३५
योहि मत्तं प्रमत्तं वासुप्तं वारहितं भृशं ।
हन्यात्सभ्रूणहा लोके त्वद्विधं मदमोहितम् ॥" ३६

सप्रहस्यात्रवीन्मन्दं क्रोधात्त मसुरोत्तमम् ।
विसृज्यताः स्त्रिय स्सर्वा स्तारा प्रभृतिका स्तदा ॥ ३७
"मत्तोऽय मिति मामंस्थायद्यभीतोऽसि संयुगे ।
मदोऽयं सम्प्रहारेऽस्मि न्वीरपाणं समर्थ्यताम् ॥" ३८
त मेव मुक्त्वा संक्रुद्धो माला मुत्क्षिप्य काञ्चनीम् ।
पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥ ३९
विषाणयो गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ।
आविद्ध्यत तदा वाली विनदन्कपिकुञ्जरः ॥ ४०
वाली व्यापादयांचक्रे ननर्दच महास्वनम् ।
श्रोत्राभ्या मथ रक्तंतु तस्य सुस्राव पात्यतः ॥ त्य ४१
तयोस्तु क्रोधसंरम्भा त्परस्परजयैषिणोः ।
युद्धं समभवद्घोरं दुन्दुभे र्वानरस्यच ॥ ४२
अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः ।
मुष्टिभि र्जानुभि श्चैव शिलाभिः पादपै स्तथा ॥ ४३
परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा ।
असह्यो नासुरो युद्धे शक्रसूनु र्व्यवर्धत ॥ ४४
व्यापारवीर्यधैर्यैं श्च परिक्षीणं पराक्रमैः ।
तंतु दुन्दुभि मुत्पाट्य धरण्या मभ्यपातयत् ॥ ४५
युद्धे प्राणहरे तस्मि न्निष्पिष्टो दुन्दुभिस्तदा ।
स्रोतोभ्योबहुरक्तंतु तस्य सुस्राव पात्यतः ॥ ४६
पपात च महाकायः क्षितौपञ्चत्व मागतः ।
तं तोलयित्वा बाहुभ्यां गतसत्त्व मचेतनम् ॥ ४७

चिक्षेप बलवा न्वाली वेगेनैकेनयोजनम् ।
तस्यवेगप्रविद्धस्य वक्त्रा त्क्षतजबिन्दवः ॥ ४८
प्रपेतु र्मारुतोत्क्षिप्ता मतङ्गस्याश्रमंप्रति ।
ता न्दृष्ट्वा पतितां स्तस्य मुनि श्शोणितविप्रुषः ॥ ४९
क्रुद्ध स्तत्र महाभाग श्चिन्तयामास "कोन्वयम् ।
येनाहं सहसा स्पृष्ट श्शोणितेन दुरात्मना ॥ ५०
कोऽयं दुरात्मा दुर्बुद्धि रकृतात्मा च बालिशः ॥"
इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिसत्तमः ॥ ५१
महिषं पर्वताकारं गतासुं पतितं भुवि ।
सतु विज्ञाय तपसा वानरेण कृतं हि तत् ॥ ५२
उत्ससर्ज महाशापं क्षेप्तारंवालिनंप्रति ।
"इहतेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ॥ ५३
वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ।
सम्भग्नाः पादपा श्चेमे क्षिप्तेहासुरींतनुम् ॥ ५४
समन्ता द्योजनं पूर्ण माश्रमं मामकं यदि ।
आगमिष्यति दुर्बुद्धि र्व्यक्तं स न भविष्यति ॥ ५५
ये चापि सचिवास्तस्य संश्रितामामकंवनम् ।
नच तै रिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५६
यदि तेऽपीहतिष्ठन्ति शपिष्ये तानपिध्रुवम् ।
वनेऽस्मि न्मामके नित्यं पुत्रवत्परिरक्षिते ॥ ५७
पत्राङ्कुरविनाशाय फलमूलाभवाय च ।
दिवस श्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् ॥ ५८

बहुवर्षसहस्राणि स वै शैलो भविष्यति ।"
तत स्ते वानरा श्शुत्वा गिरं मुनिसमीरिताम् ॥ ५९
निश्चक्रमु र्वना त्तस्मा त्ता न्दृष्ट्वा वालि रब्रवीत् ।
"किं भवन्त स्समस्ताश्च मतङ्गवनवासिनः ॥ ६०
मत्समीप मनुप्राप्ता अपि स्वस्ति वनौकसाम् ।"
तत स्तेकारणं सर्वं तदा शापंच वालिनः ॥ ६१
शशंसु र्वानरास्सर्वे वालिने हेममालिने ।
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ॥ ६२
'स महर्षिं तदासाद्य याचतेस्म कृताञ्जलिः ।
महर्षि स्त मनादृत्य प्रविवेशाश्रमं तदा ॥ ६३
शापधारणभीत स्तु वाली विह्वलतां गतः ।
तत श्शापभयाद्भीत ऋश्यमूकं महागिरिम् ॥ ६४
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ! ।
तस्याप्रवेशंज्ञात्वाऽह मिदं राम ! महावनम् ॥ ६५
विचरामि सहामात्यो विषादेन विवर्जितः ।
एषोऽस्थिनिचय स्तस्य दुन्दुभे स्संप्रकाशते ॥ ६६
वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ।
इमे च विपुला स्साला स्सप्त शाखावलम्बिनः ॥ ६७
यत्रैकं घटते वाली निष्पत्रयितु मोजसा ।
एत दस्यासमंवीर्यं मया राम ! प्रकीर्तितम् ॥ ६८
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ! ।"
तथाब्रुवाणं सुग्रीवं प्रहसन्लक्ष्मणोऽब्रवीत् ॥ ६९

कस्मिन्कर्मणिनिर्वृत्ते श्रद्दध्या वालिनो वधम् ।"
त मुवाचाथ सुग्रीव स्सप्त सालानिमान्पुरा ॥ ७०
एव मेकैकशो वाली विव्याधाथ स चासकृत् । धा
रामोऽपि दारयेदेषां बाणेनैकेन चे द्रुमम् ॥ ७१
वालिनं निहतं मन्येदृष्ट्वारामस्याविक्रमम् ।
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण! ॥ ७२
उद्यम्याथ प्रक्षिपे चेत्तरसा द्वे धनुश्शते ।"
एव मुक्त्वातु सुग्रीवो रामंरक्तान्तलोचनम् ॥ ७३
ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ।
"शूरश्च शूरघातीचप्रख्यातबलपौरुषः ॥ ७४
बलवान्वानरो वालीसंयुगेष्वपराजितः ।
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ॥ ७५
यानि संचिन्त्य भीतोऽहं मृश्यमूकं समाश्रितः ।
त मजय्य मधृष्यं च वानरेन्द्र मसर्षणम् ॥ ७६
विचिन्तय न्नमुञ्चामि ऋश्यमूक महं त्विमम् ।
उद्विग्नश्शङ्कित श्चापि विचरामि महावने ॥ ७७
अनुरक्तै स्सहामात्यै र्हनुमत्प्रमुखैर्वरैः ।
उपलब्धं च मे श्राद्ध्यं सन्मित्रं मित्रवत्सल! ॥ ७८
त्वा महं पुरुषव्याघ्र! हिमवन्त मिवाश्रितः ।
किंतु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः ॥ ७९
अप्रत्यक्षं तु मे वीर्यं समरे तव राघव! ।
न खल्वहं त्वां तुलये नावमन्ये न भीषये ॥ ८०

कर्मभि स्तस्य भीमै स्तु कातर्यं जनितंमम ।
कामं राघव ! ते वाणी प्रमाणं धैर्य माकृतिः ॥ ८१
सूचयन्ति परं तेजो भस्मच्छन्न मिवानलम् ।"
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ॥ ८२
स्मितपूर्व मथो रामः प्रत्युवाच हरिं प्रभुः ।
"यदि नप्रत्ययोऽस्मासु विक्रमे तव वानर ! ॥ ८३
प्रत्ययं समरे श्लाघ्य महमुत्पादयामि ते ।"
एव मुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः ॥ ८४
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ।
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ८५
असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान् ।
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ॥ ८६
लक्ष्मणस्यागतोराम मिदं वचन मर्थवत् ।
"आर्द्र स्समांसः प्रत्ययः क्षिप्तः कायः पुरा सखे ॥ ८७
लघुस्सम्प्रति निर्मांस स्तृणभूतश्चराघव ! ।
परिश्रान्तेनमत्तेन भ्रात्रामेवालिनातदा ॥ ८८
क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ! ।
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥ ८९
'आर्द्र शुष्क मितिह्येत त्सुमहद्राघवान्तरम् ।
स एव संशय स्तात ! तव तस्य च यद्बले ॥ ९०
साल मेकंतु निर्भिन्द्याभवेद्व्यक्ति र्बलाबले ।
कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ॥ ९१

आकर्णपूर्णं मार्वस्य विसृजस्व महाशरम् ।
इमं हि सालं संहितस्त्वया शरो नसंशयोऽत्रास्ति विदारयिष्यति ।
अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज ! शापितो मया ॥
यथा हि तेजस्सु वरस्सदा रविर्यथाहि शैलो हिमवान्महाद्रिषु ।
यथा चतुष्पात्सुच केसरी वरस्तथा नराणामसि विक्रमे वरः ॥"

इति श्रीमत्किष्किन्धाकाण्डे एकादशस्सर्गः ॥

॥ द्वादशस्सर्गः ॥

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १
स गृहीत्वा धनुर्घोरं शरमेकंच मानदः ।
साल मुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः ॥ २
स विसृष्टो बलवता बाणस्त्वर्ण परिष्कृतः ।
भित्त्वा सालान्गिरिप्रस्थे सप्तभूमिं विवेशह ॥ ३
प्रविश्य च मुहूर्तेन धरां भित्त्वा महाजवः ।
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥ ४
तान्दृष्ट्वा सप्त निर्भिन्नां स्तालान्वानरपुङ्गवः ।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ ५
समूर्ध्वा न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥ ६
इदंचो वाच धर्मज्ञं कर्मणातेन हर्षितः ।
"रामं सर्वास्त्र विदुषां श्रेष्ठं शूरमवस्थितम् ॥ ७

सेन्द्रानपि सुरां त्सर्वां स्त्वं बाणैः पुरुषर्षभ! । स्त्वं
समर्थ स्समरेहन्तुं किंपुन र्वालिनं प्रभो! ॥ ८
येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।
बाणे नैकेन काकुत्स्थ! स्थाताते त्रीरणाग्रतः ॥ को ९
अद्यमे विगतश्शोकः प्रीतिरद्य परामम ।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १०
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।
वालिनं जहि काकुत्स्थ! मया बद्धोऽय मञ्जलिः ॥" ११
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२
"अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छत्वमग्रतः ।
गत्वा चाह्वय सुग्रीव! वालिनं भ्रातृगन्धिनम् ॥" १३
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।
वृक्षैरात्मान मावृत्य व्यतिष्ठन्गहने वने ॥ १४
सुग्रीवो व्यनदद्घोरं वालिनोऽऽह्वानकारणात् ।
गाढं परिहतो वेगान्नादै र्भिन्दन्निवाम्बरम् ॥ १५
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।
निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव ॥ १६
ततस्सु तुमुलं युद्धं वालिसुग्रीवयो रभूत् ।
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥ १७
[अभ्रचर्कयो र्यथाऽकाशे मेरुमन्दरयोरिव ।
हिमवद्विन्ध्ययो श्चैव यथा मैनाकक्रौञ्चयोः ॥ १८

वज्रगोकर्णयो श्चैव महेन्द्रारिष्टयोरिव ।]
तलै रशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥ १९
जघ्नतु स्समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।
ततो रामो धनुष्पाणि स्तावुभौ समुदीक्ष्यतु ॥ २०
अन्योन्यसदृशौ वीरा वुभौ देवा विवाश्विनौ ।
यन्नावगच्छ त्सुग्रीवं वालिनं वापि राघवः ॥ २१
ततो न कृतवान्बुद्धिं मोक्तु मन्तकरं शरम् ।
एतस्मिन्नन्तरे भग्नस्सुग्रीवस्तेन वालिना ॥ २२
अपश्य न्राघवं नाथ मृश्यमूकं प्रदुद्रुवे ।
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्झरीकृतः ॥ २३
वालिनाऽभिद्रुतः क्रोधात्प्रविवेश महावनम् ।
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः ॥ २४
'मुक्तोह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ।
[निवृत्त स्स्वपुरीं प्रायात्क्रोधाविष्टो महाबलः ॥] २५
राघवोऽपि सहभ्रात्रा सहचैव हनूमता ।
तदेव वनमागच्छ त्सुग्रीवो यत्र वानरः ॥ २६
तं समीक्ष्यागतं रामं सुग्रीव स्सहलक्ष्मणम् ।
ह्रीमान्दीन मुवाचेदं वसुधा मवलोकयन् ॥ २७
'आह्वय'स्वेति मा मुक्त्वा दर्शयित्वा च विक्रमम् ।
वैरिणा घातयित्वाच किमिदानीं त्वया कृतम् ॥ २८
ता मेव वेळां वक्तव्यं त्वया राघव ! तत्त्वतः ।
वालिनं न निहन्मीति ततो नाह मितोव्रजे ॥" २९

तस्यचैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ ३०
"सुग्रीव! श्रूयतां तात! क्रोधश्चव्यपनीयताम् ।
कारणं येन बाणोऽयं न मया स विसर्जितः ॥ ३१
अलंकारेण वेषेण प्रमाणेन गतेन च ।
त्वंच सुग्रीव! वालीच सदृशौ स्थः परस्परम् ॥ ३२
स्वरेण वर्चसा चैव प्रेक्षितेनच वानर! ।
विक्रमेणच वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥ ३३
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम! ।
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ॥ ३४
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ।
मूलघातो ननौस्याद्विद्वयो रपिकृतो मया ॥ ३५
त्वयि वीरे विपन्नेहि अज्ञानाल्लाघवान्मया ।
मौढ्यंच मम बाल्यंच ख्यापितं स्यात्कपीश्वर ॥ ३६
दत्ताभयवधोनाम पातकं महदुच्यते ।
अहंच लक्ष्मणश्चैव सीताच वरवर्णिनी ॥ ३७
त्वदधीना वयं सर्वेवनेऽस्मिन् शरणं भवान् ।
तस्मा द्युध्यस्व भूयस्त्वं मामा शङ्कीश्च वानर! ॥ ३८
एतन्मुहूर्ते सुग्रीव! पश्य वालिन माहवे ।
निरस्त मिषुणैकेन वेष्टमानं महीतले ॥ ३९
अभिज्ञानं कुरुष्व त्व मात्मनो वानरेश्वर! ।
येन त्वा मभिजानीयां द्वन्द्वयुद्ध मुपागतम् ॥" ४०

गजपुष्पी मिमां फुल्ला मुत्पाट्य शुभलक्षणाम् ।
कुरु लक्ष्मण! कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥" ४१
ततो गिरितटे जाता मुत्पाट्य कुसुमाकुलाम् ।
लक्ष्मणो गजपुष्पीं तां तस्यकण्ठे व्यसर्जयत् ॥ ४२
स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ।
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ४३
मालयेव बलाकानां ससन्ध्य इवतोयदः ।
विभ्राजमानो वपुषा रामवाक्य समाहितः ॥ ४४
जगाम सह रामेण किष्किन्धां वालिपालिताम् ।

इति श्रीमत्किष्किन्धाकाण्डे द्वादशस्सर्गः ॥

॥ त्रयोदशस्सर्गः ॥

ऋश्यमूका त्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।
जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।
शरां श्चादित्यसङ्काशा न्गृहीत्वा रणसाधकान् ॥ २
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।
सुग्रीव स्संहतग्रीवो लक्ष्मण श्च महाबलः ॥ ३
पृष्ठतो हनुमा न्वीरो नळो नील श्च वानरः ।
तारश्चैव महातेजा हरियूथपयूथपः ॥ ४
ते वीक्षमाणा वृक्षां श्च पुष्पभारावलम्बिनः ।
प्रसन्नाम्बुवहा श्चैव सरित स्सागरंगमाः ॥ ५

कन्दराणिच शैलां श्च निर्दराणि गुहा स्तथा ।
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ६
वैडूर्यविमलैःपर्णैः पद्मै श्चाकोशकुट्मलैः ।
शोभितां त्सजला न्मार्गे तटाकां श्च व्यलोकयन् ॥ ७
कारण्डै स्सारसैर्हंसै र्वञ्जुळै र्जलकुक्कुटैः ।
चक्रवाकै स्तथाचान्यै श्शकुनै रुपनादितान् ॥ ८
मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान् ।
चरत स्सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान् ॥ ९
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।
घोरा नेकचरा न्वन्या न्द्विरदा न्कूलघातिनः ॥ ११
मत्ता न्गिरितटोत्कृष्टा न्पर्वता निव जङ्गमान् ।
वारणा न्वारिदप्रख्या न्महीरेणुसमुक्षितान् ॥ ११
वने वनचरां श्चान्यान्खेचरां श्च विहङ्गमान् ।
पश्यन्त स्त्वरिता जग्मु स्सुग्रीववशवर्तिनः ॥ १२
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।
द्रुमषण्डं वनं दृष्ट्वा रामस्सुग्रीव मब्रवीत् ॥ १३
" एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।
मेघसङ्घातविपुलः पर्यन्तकदळीवृतः ॥ १४
किं मेतत् ज्ञातु मिच्छामि सखे ! कौतूहलं हि मे ।
कौतूहलापनयनं कर्तु मिच्छाम्यहं त्वया ॥ " १५
तस्यतद्वचनं श्रुत्वा राघवस्य महात्मनः ।
गच्छन्ने वाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ॥ १६

"एत द्राघव! विस्तीर्णं माश्रमं श्रमनाशनम्।
उद्यानवनसंपन्नं स्वादुमूलफलोदकम्॥ १७
अत्र सप्तजना नाम मुनय स्संशितव्रताः।
सप्तैवासन्नधश्शीर्षा नियतं जलशायिनः॥ १८
सप्तरात्रकृताहारा वायुना वनवासिनः।
दिवं वर्षशतै र्याता स्सप्तभि स्सकळेबराः॥ १९
तेषा मेवंप्रभावानां द्रुमप्राकारसंवृतः।
आश्रम स्सुदुराधर्ष अपि सेन्द्रै स्सुरासुरैः॥ २०
पक्षिणो वर्जयन्त्येतत्तथाऽन्ये वनचारिणः।
विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः॥ २१
विभूषणरवा स्तत्र श्रूयन्ते सकलाक्षराः।
तूर्यगीतस्वरा श्चात्र गन्धो दिव्य श्च राघव!॥ २२
श्वेताभ्रयोऽपि दीप्यन्ते धूमो यत्र प्रकाशते।
वेष्ट्यानिव वृक्षाग्रा न्कपोताङ्गारुणो घनः॥ २३
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः।
मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा॥ २४
कुरु प्रणामं धर्मात्मं स्तां त्समुद्दिश्य राघव!।
लक्ष्मणेन सहभ्रात्रा प्रयतस्संयताञ्जलिः॥ २५
प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम्।
न तेषा मशुभं किंचिच्छरीरे राम! दृश्यते॥" २६
ततो राम स्सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः।
समुद्दिश्य महात्मान स्ता नृषी नभ्यवादयत्॥ २७

अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः ।
सुग्रीवो वानरा श्चैव जग्मु स्संहृष्टमानसाः ॥ २८
ते गत्वा दूर मध्वानं तस्मात्सप्तजनाश्रमात् ।
ददृशु स्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ २९
तत स्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः ।
पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागता स्सह ॥ ३०

इति श्रीमत्किष्किन्धाकाण्डे त्रयोदशस्सर्गः ॥

॥ चतुर्दशस्सर्गः ॥

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् ।
वृक्षै रात्मान मावृत्य व्यतिष्ठन्गहने वने ॥ १
विचार्य सर्वतो दृष्टिं कानने काननप्रियः । सा
सुग्रीवो विपुलग्रीवः क्रोध माहारय द्भृशम् ॥ २
तत स्स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ।
परिवारैः परिवृतो नादै र्भिन्दन्निवाम्बरम् ॥ ३
गर्जन्निव महामेघो वायुवेगपुरस्सरः ।
अथ बालार्कसदृशो दृप्तसिंहगति स्तदा ॥ ४
दृष्ट्वा रामं क्रियादक्षं सुग्रीवोवाक्यमब्रवीत् ।
" हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ॥ ५
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ।
प्रतिज्ञा या त्वया वीर! कृता वालिवधे पुरा ॥ ६

सफलां तां कुरु क्षिप्रं लतां काल इवागतः ।"
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ॥ ७
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः ।
"कृताभिज्ञानचिह्न स्त्व मनया गजसाह्वया ॥ ८
लक्ष्मणेनसमुत्पाट्य यैषा कण्ठे कृता तव ।
शोभसे ह्यधिकं वीर! लतया कण्ठसक्तया ॥ ९
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।
अद्य वालिसमुत्थं ते भयं वैरं च वानर! ॥ १०
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ।
मम दर्शय सुग्रीव! वैरिणं भ्रातृरूपिणम् ॥ ११
वाली विनिहतो याव द्वने पांसुषु वेष्टते ।
यदि दृष्टिपथं प्राप्तो जीवं स्स न निवर्तते ॥ १२
ततो दोषेण मागच्छे स्सद्यो गर्हे च मा भवान् ॥
प्रत्यक्षं सप्त ते सालामया बाणेन दारिताः ॥ १३
तेनावेहि बलेनाद्यवालिनं निहतं मया ।
अनृतं नोक्तपूर्वं मे वीर! कृच्छ्रेऽपि तिष्ठता ॥ १४
धर्मलोभपरीतेन नचवक्ष्ये कथंचन ।
सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ॥ १५
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ।
तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः ॥ १६
सुग्रीव! कुरु तं शब्दं निष्पते द्येन वानरः ।
जितकाशी बलश्लाघी त्वया चाधर्षितः पुरात् ॥ १७

निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः ।
रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे ॥ १८
जानन्त स्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ।"
सतु रामवच श्शुत्वा सुग्रीवो हेमपिङ्गळः ॥ १९
ननर्द क्रूरनादेन विनिर्भिन्द न्निवाम्बरम् ।
तस्य शब्देन विस्रस्ता गावो यान्ति हतप्रभाः ॥ २०
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ।
द्रवन्ति च मृगा श्शीघ्रं भग्ना इव रणे हयाः ॥ २१
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ।
तत स्स जीमूतगणप्रणादो नादं ह्यमुञ्चत्स्वरया प्रतीतः ।
सूर्यात्मज श्शौर्यविवृद्धतेजा स्सरित्पति र्वाऽनिलचञ्चलोर्मिः ॥ २२

इति श्रीमत्किष्किन्धाकाण्डे चतुर्दशस्सर्गः ॥

॥ पञ्चदशस्सर्गः ॥

अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ।
शुश्रावान्तःपुरगतोवाली भ्रातु रमर्षणः ॥ १
श्रुत्वातु तस्य निनदं सर्वभूतप्रकम्पनम् ।
मदश्चैकपदे नष्टः क्रोध श्चापतितो महान् ॥ २
सतु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः ।
उपरक्त इवादित्य स्सद्यो निष्प्रभतां गतः ॥ ३
वाली दंष्ट्राकराळ स्तु क्रोधा दीप्ताग्निसन्निभः ।
भात्युत्पतितपद्मस्तु समृणाळ इवह्रदः ॥ ४

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५
तं तु तारा परिष्वज्य स्नेहा दर्शितसौहृदा ।
उवाच त्रस्तसंभ्रान्ता हितोदर्कं मिदं वचः ॥ ६
साधु क्रोध मिमं वीर! नदीवेग मिवागतम् ।
शयना दुत्थितः काल्यं त्यज मुक्ता मिव स्रजम् ॥ ७
काल्यमेतेन संग्रामं करिष्यासिच वानर! ।
वीर! ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ ८
सहसा तव निष्क्रामो मम ताव न्नरोचते ।
श्रूयतांचाभिधास्यामि यन्निमित्तं निवार्यसे ॥ ९
पूर्वं मापतितः क्रोधा त्स त्वामाह्वयते युधि ।
निष्पत्य च निरस्त स्ते हन्यमानो दिशो गतः ॥ १०
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।
इहैत्य पुन राह्वानं शङ्कां जनयतीव मे ॥ ११
दर्प श्च व्यवसाय श्च यादृश स्तस्य नर्दतः ।
निनाद श्चापि संरम्भो नैतदल्पं हि कारणम् ॥ १२
नासहाय महं मन्ये सुग्रीवं तमिहागतम् ।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ १३
प्रकृत्या निपुण श्चैव बुद्धिमां श्चैव वानरः ।
अपरीक्षितवीर्येण सुग्रीव स्सह नैष्यति ॥ १४
पूर्व मेव मया वीर! श्रुतं कथयतो वचः ।
अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ १५

अङ्गद स्तु कुमारोऽयं यौवनान्त मुपनिर्गतः ।
प्रवृत्ति स्तेन कथिता चारै राप्तै र्निवेदिता ॥ १६
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ ।
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥ १७
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ।
तव भ्रातु र्हि विख्यात स्सहायो रणकर्कशः ॥ १८
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ।
निवासवृक्ष स्साधूना मापन्नानां परागतिः ॥ १९
आर्तानां संश्रय श्चैव यशस श्चैक भाजनम् ।
ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ॥ २०
धातूना मिव शैलेन्द्रो गुणाना माकरो महान् ।
तत्क्षमं नविरोध स्ते सहतेन महात्मना ॥ २१
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ।
शूर ! वक्ष्यामि ते किंचि न्न चेच्छाम्यभ्यसूयितुम् ॥ २२
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ।
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ॥ २३
विग्रहं मा कृथावीर ! भ्रात्रा राज ! न्बलीयसा ।
अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ॥ २४
सुग्रीवेणच संप्रीतिं वैर मुत्सृज्य दूरतः ।
लालनीयो हि ते भ्रातायवीयानेष वानरः ॥ २५
तत्र वा स न्निहस्थोवा सर्वथा बन्धु रेवते ।
नहि तेन समं बन्धुं भुवि पश्यामि कंचन ॥ २६

दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ।
वैर मेत त्समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥ २७
सुग्रीवो विपुलग्रीव स्तव बन्धु स्सदा मतः ।
भ्रातु स्सौहृद मालम्ब्य नान्या गतिरिहास्तिते ॥ २८
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २९
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोष मेवानुविधातु मर्हसि ।
क्षमोहि ते कोसलराजसूनुना नविग्रहः शक्रसमानतेजसा ॥ ३०
तदाहि तारा हितमेव वाक्यं तं वालिनं पथ्य मिदं बभाषे ।
नरोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ॥ ३१

इति श्रीमत्किष्किन्धाकाण्डे पञ्चदशस्सर्गः ॥

॥ षोऽशस्सर्गः ॥

तामेवं ब्रुवतीं तारां तारा धिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेद मब्रवीत् ॥ १
गर्जतोऽस्यच संरम्भं भ्रातु श्शक्तो र्विशेषतः ।
मर्षयिष्याम्यहं केन कारणेन वरानने !॥ २
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
घर्षणामर्षणं भीरु ! मरणा दतिरिच्यते ॥ ३
सोढुं नच समर्थोऽहं युद्धकामस्यच संयुगे ।
सुग्रीवस्यच संरम्भं हीनग्रीवस्य गर्जतः ॥ ४

न च कार्यो विषाद स्ते राघवं प्रतिमत्कृते।
धर्मज्ञ श्च कृतज्ञ श्च कथं पापं करिष्यति ॥ ५
निवर्तस्व सह स्त्रीभिः कथंभूयोऽनुगच्छसि ।
सौहृदं दर्शितं तारे! मयि भक्तिः कृता त्वया ॥ ६
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।
दर्पमात्रंविनेष्यामि नचप्राणै र्विमोक्ष्यते ॥ ७
अहं ह्याजौ स्थितस्यास्य करिष्यामि यथेप्सितम् ।
वृक्षै र्मुष्टिप्रहारै श्च पीडितः प्रतियास्यति ॥ ८
न मे गर्वित मायत्तं सहिष्यति दुरात्मवान् ।
कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ॥ ९
शापितासि मम प्राणै र्निवर्तस्व जयेनच ।
अहं जित्वा निवर्तिष्ये तं मरिंभ्रातरं रणे ॥" १०
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ११
तत स्स्वस्त्ययनं कृत्वा मन्त्रविद्विजयैषिणी ।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२
प्रविष्टायां तु तारायां सह स्त्रीभि स्स्व मालयम् ।
नगरा न्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ १३
स निःश्वस्य महातेजा वाली परमरोषणः ।
सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ १४
स ददर्श तत श्श्रीमां स्सुग्रीवं हेमपिङ्गळम् ।
सुसंवीत मवष्टब्धं दीप्यमान मिवानलम् ॥ १५

स तं दृष्ट्वामहावीर्यं सुग्रीवं पर्यवस्थितम् ।
गाढं परिदधे वासो वाली परमरोषणः ॥ १६
स वाली गाढसंवीतो मुष्टि मुद्यम्य वीर्यवान् ।
सुग्रीव मेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ १७
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ।
सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८
तं वाली क्रोधताम्राक्ष स्सुग्रीवं रणपण्डितम् ।
आपतन्तं महावेग मिदं वचन मब्रवीत् ॥ १९
"एष मुष्टिर्मया बद्धो गाढ स्सन्निहिताङ्गुळिः ।
मया वेगविमुक्तस्ते प्राणा नादाय यास्यति ॥" २०
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिन मब्रवीत् ।
"तवैवचाहरन्प्राणा न्मुष्टिः पततु मूर्धनि ॥" २१
ताडित स्तेन संक्रुद्धस्ससमभिक्रम्य वेगितः ।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ २२
सुग्रीवेण तु निस्सङ्गं साल मुत्पाट्य तेजसा ।
गात्रे ष्वभिहतो वाली वज्रेणेव महागिरिः ॥ २३
सतुवाली प्रचलित स्सालताडनविह्वलः ।
गुरुभारसमाक्रान्तो नौः सार्थैरिव सागरे ॥ २४
तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥ २५
परस्पर ममित्रघ्नौ च्छिद्रान्वेषणतत्परौ ।
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ॥ २६

सूर्यपुत्रो महावीर्य स्सुग्रीवः परिहीयते ।
वालिना भग्नदर्प स्तु सुग्रीवो मन्दविक्रमः ॥ २७
वालिनं प्रति सामर्षो दर्शयामास लाघवम् ।
वृक्षै स्सशाखै स्ससिखै र्वज्रकोटिनिभै र्नखैः ॥ २८
मुष्टिभि र्जानुभिः पद्भिर्बाहुभिश्च पुनःपुनः ।
तयोर्युद्ध मभू द्घोरं वृत्रवासवयोरिव ॥ २९
तौ शोणितार्क्तौ युध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दैस्तर्जयानौ परस्परम् ॥ ३०
हीयमान मथोऽपश्यत्सुग्रीवं वानरेश्वरम् ।
वीक्षमाणं दिश श्चैव राघव स्स मुहुर्मुहुः ॥ ३१
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ ३२
ततो धनुषि सन्धाय शर माशीविषोपमम् ।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥ ३३
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्रुवु र्मृगा श्चैव युगान्त इव मोहिताः ॥ ३४
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ ३५
तत स्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥ ३६
इन्द्रध्वज इवोद्भूतः पौर्णमास्यां महीतले ।
आश्वयुक्समये मासि गतश्रीकोविचेतनः ॥ ३७

नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् ।
ससर्ज दीप्तं तममित्रमर्दनं सधूम मग्निं मुखतो यथा हरः ॥ ३८
अथोक्षितश्शोणिततोयविस्रवैस्सुपुष्पिताशोक इवानलोद्धतः ।
विचेतनो वासवसूनु राहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३९

इति श्रीमत्किष्किन्धाकाण्डे षोडशस्सर्गः ॥

॥ सप्तदशस्सर्गः ॥

तत श्शरेणाभिहतो रामेण रणकर्कशः ।
पपात सहसा वाली निकृत्त इव पादपः ॥ १
स भूमौ न्यस्तसर्वाङ्ग स्तप्तकाञ्चनभूषणः ।
अपत देवराजस्य मुक्तरश्मि रिव ध्वजः ॥ २
तस्मि न्निपतिते भूमौ वानराणां गणेश्वरे ।
नष्टचन्द्र मिव व्योम न व्यराजत भूतलम् ॥ ३
भूमौ निपतितस्यापि तस्यदेहं महात्मनः ।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ ४
शक्रदत्ता वरामाला काञ्चनी वज्रभूषिता ।
दधार हरिमुख्यस्य प्राणां स्तेज श्रियं च सा ॥ ५
स तया मालया वीरो हैमया हरियूथपः ।
सन्ध्यानुगत पर्यन्तः पयोधर इवाभवत् ॥ ६
तस्य माला च देहश्च मर्मघातीचयश्शरः ।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७

तदस्य तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।
रामबाणासनक्षिप्त मावह त्परमां गतिम् ॥ ८
तं तदापतितं संख्ये गतार्चिष मिवानलम् ।
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव ॥ ९
ययाति मिव पुण्यान्ते देवलोका त्परिच्युतम् ।
आदित्य मिव कालेन युगान्ते भुवि पातितम् ॥ १०
महेन्द्र मिव दुर्धर्षं महेन्द्र मिव दुस्सहम् ।
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ॥ ११
सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।
लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ १२
तं दृष्ट्वा राघवं वाली लक्ष्मणंच महाबलम् ।
अब्रवी त्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ १३
"त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः ।
कुलीन स्सत्त्वसंपन्न स्तेजस्वी चरितव्रतः ॥ १४
पराङ्मुखवधं कृत्वा कोनु प्राप्तस्त्वया गुणः ।
यदहं युद्धसंरब्धश्शरेणोरसि ताडितः ॥ १५
रामः करुणवेदीच प्रजानांच हिते रतः ।
सानुक्रोशो जितोत्साह स्समयज्ञो दृढव्रतः ॥ १६
इति ते सर्वभूतानि कथयन्ति यशो भुवि ।
दम श्शमः क्षमाधर्मो धृतिस्सत्यं पराक्रमः ॥ १७
पार्थिवानां गुणा राजन्दण्डश्चाप्यपराधिषु ।
तान्गुणांत्संप्रधार्याह मद्यं चाभिजनं तव ॥ १८

तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः ।
न मा मन्येन संरब्धं प्रमत्तं योद्धु मर्हति ॥ वे १९
इति मे बुद्धि रुत्पन्ना बभूवादर्शने तव ।
न त्वां विनिहतात्मानं धर्मध्वज मधार्मिकम् ॥ २०
जाने पापसमाचारं तृणैः कूपमिवावृतम् ।
सतां वेषधरं पापं प्रच्छन्न मिव पावकम् ॥ २१
नाहं त्वा मभिजानामि धर्मच्छद्माभिसंवृतम् ।
विषये वा पुरे वा ते यदा नापकरोम्यहम् ॥ २२
नचत्वा मवजाने च कस्मात्त्वं हंस्याकिल्बिषम् ।
फलमूलाशिनं नित्यं वानरं वनगोचरम् ॥ २३
मामिहाप्रतियुध्यन्तमन्येन च समागतम् ।
लिङ्गमप्यस्तिते राजन्! दृश्यते धर्मसंहितम् ॥ २४
कः क्षत्रियकुले जातश्रुतवा न्नष्टसंशयः ।
धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्मसमाचरेत् ॥ २५
राम! राजकुले जातो धर्मवानिति विश्रुतः ।
अभव्यो भव्यरूपेण किमर्थं परिधावसि ॥ २६
सामदानं क्षमाधर्म स्सत्यंधृतिपराक्रमौ ।
पार्थिवानां गुणा राजन्! दण्डश्चाप्यपराधिषु ॥ २७
वयं वनचरा राम! मृगा मूलफलाशनाः ।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ २८
भूमिर्हिरण्यं रूप्यंच विग्रहे कारणानिच ।
अत्रकस्ते वने लोभो मदीयेषु फलेषु वा ॥ २९

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ।
राजवृत्ति रसंकीर्णा न नृपाः कामवृत्तयः ॥ ३०
त्वंतु कामप्रधानश्च कोपन श्चानवस्थितः ।
राजवृत्तैश्च संकीर्णश्शरासनपरायणः ॥ ३१
नतेऽस्त्यर्थचिति धर्मे नार्थे बुद्धिरवस्थिता ।
इन्द्रियैः कामवृत्तस्स न्कृष्यसे मनुजेश्वर ! ॥ ३२
हत्वा बाणेन काकुत्स्थ ! मा मिहानपराधिनम् ।
किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ ३३
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधेरतः ।
नास्तिकः परिवेत्ताच सर्वे निरयगामिनः ॥ ३४
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः ।
लोकं पापात्मना मेते गच्छन्ते नात्रसंशयः ॥ ३५
अधार्यं चर्ममे सद्भीरोमाण्यस्थिचवर्जितम् ।
अभक्ष्याणिच मांसानि त्वद्विधै र्धर्मचारिभिः ॥ ३६
पञ्चपञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव ! ।
शल्यकश्श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥ ३७
चर्मचास्थिच मे राजन् ! नस्पृशन्ति मनीषिणः ।
अभक्ष्याणिच मांसानि सोऽहं पञ्चनखो हतः ॥ ३८
तारया वाक्य मुक्तोऽहं सत्यं सर्वज्ञया हितम् ।
तदतिक्रम्य मोहेन कालस्य वशमागतः ॥ ३९
त्वया नाथेन काकुत्स्थ ! न सनाथा वसुन्धरा ।
प्रमदा शीलसंपन्ना धूर्तेन पतिना यथा ॥ ४०

शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ।
कथं दशरथेन त्वं जातः पापो महात्मना ॥ ४१
छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना ।
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ ४२
अशुभं चाप्ययुक्तंच सतां चैव विगर्हितम् ।
वक्ष्यसे चेदृशं कृत्वा सद्भिस्सह समागतः ॥ ४३
उदासीनेषु योऽस्मासु विक्रमस्ते प्रकाशितः ।
अपकारिषु तं राज! न्नहि पश्यामि विक्रमम् ॥ ४४
दृश्यमानस्तु युद्ध्येथा मया यदि नृपात्मज! ।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ ४५
त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः ।
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ ४६
मामेव यदि पूर्वं त्वमेतदर्थं मघोदयः ।
मैथिली मह मेकाह्ना तव चानीतवान्भवेत्॥ ४७
सुग्रीव प्रियकामेन यत्कृतेऽस्मि हतस्त्वया ।
कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे ॥ ४८
न्यस्तां सागरतोये वा पाताळे वापि मैथिलीम् ।
आनयेयं तवादेशा च्छ्वेता मश्वतरीमिव ॥ ४९
युक्तं यत्प्राप्नुया द्राज्यं सुग्रीव स्स्वर्गते मयि ।
अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ॥ ५०
काम मेवं विधो लोकः कालेन विनियुज्यते ।
क्षमं चेद्भवता प्राप्तमुत्तरं साधुचिन्त्यताम् ॥" ५१

इत्येव मुक्त्वा परिशुष्कवक्त्र श्शराभिघाता व्यथितो महात्मा ।
समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराजसूनुः ॥ ५२

इति श्रीमत्किष्किन्धाकाण्डे सप्तदशस्सर्गः ॥

॥ अष्टादशस्सर्गः ॥

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ॥ १

तं निष्प्रभ मिवादित्यं मुक्ततोय मिवाम्बुदम् ।
उक्तवाक्यं हरिश्रेष्ठ मुपशान्त मिवानलम् ॥ २

धर्मार्थगुणसंपन्नं हरीश्वर मनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिन मब्रवीत् ॥ ३

"धर्ममर्थंच कामंच समयं चापिलौकिकम् ।
अविज्ञाय कथं बाल्या न्मामिहाद्य विगर्हसे ॥ ४

अपृष्ट्वा बुद्धिसंपन्ना न्वृद्धा नाचार्यसम्मतान् ।
सौम्यं वानरचापल्या किं मां वक्तु मिहेच्छसि ॥ त्वं ५

इक्ष्वाकूणा मियं भूमिस्स शैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥ ६

तां पालयति धर्मात्मा भरतस्सत्यवागृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ ७

नयश्च विनयश्चोभौ यस्मिं स्त्सत्यंच सुस्थितम् ।
विक्रमश्च यथा दृष्टस्स राजा देशकालवित् ॥ ८

तस्य धर्मकृतादेशावयं मन्येच पार्थिवाः ।
चरामो वसुधां कृत्स्नां धर्मसन्तान मिच्छवः ॥ ९
तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले ।
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥ १०
ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः ।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥ ११
त्वं तु संक्लिष्ट धर्मेण कर्मणाच विगर्हितः । इच
कामतन्त्र प्रधानश्च नस्थितो राजवर्त्मनि ॥ १२
ज्येष्ठो भ्राता पितावैव यश्च विद्यां प्रयच्छति ।
त्रयस्ते पितरोज्ञेया धर्मेपथि हि वर्तिनः ॥ १३
यवीया नात्मनः पुत्र शिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिन्त्या धर्मज्ञे दत्त कारणम् ॥ १४
सूक्ष्मः परमदुर्ज्ञेय स्सतां धर्मः प्लवङ्गम ! ।
हृदिस्थ स्सर्वभूताना मात्मा वेद शुभाशुभम् ॥ १५
चपल श्चपलैस्सार्धं वानरै रकृतात्मभिः ।
जात्यन्ध इव जात्यन्धै र्मन्त्रयन् द्रक्ष्यसे नुकिम् ॥ १६
अहं तु व्यक्तता मस्य वचनस्य ब्रवीमि ते ।
नहि मां केवलं रोषा त्त्वं विगर्हितु मर्हसि ॥ १७
तदेत त्कारणं पश्य यदर्थं त्वं मया हतः ।
भ्रातु र्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥ १८
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायां वर्तसे कामा त्स्नुषायां पापकर्मकृत् ॥ १९

तत्र्यतीतस्य ते धर्मात्कामवृत्तस्य वानर! ।
भ्रातृभार्यावमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥ २०
नहि धर्मविरुद्धस्य लोकवृत्ता दपेयुषः ।
दण्डा दन्यत्र पश्यामि निग्रहंहरियूथप ॥ २१
नहि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ।
औरसीं भगिनीं वापि भार्यां वा प्यनुजस्य यः ॥ २२
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ।
भरत स्तु महीपालो वयं त्वादेशवर्तिनः ॥ २३
त्वं तु धर्मा दतिक्रान्तः कथं शक्य उपेक्षितुम् ।
गुरु र्धर्मव्यतिक्रान्तं प्राज्ञोधर्मेण पालयन् ॥ २४
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ।
वयं तु भरतादेशविधिं कृत्वा हरीश्वर! ॥ २५
त्वद्विधान्भिन्नमर्यादा न्नियन्तुं पर्यवस्थिताः ।
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथातथा ॥ २६
दाररा ज्यनिमित्तं च निःश्रेयस्करः स्स मे ।
प्रतिज्ञाच मया दत्ता तदा वानरसन्निधौ ॥ २७
प्रतिज्ञाच कथं शक्या मद्विधेनानवेक्षितुम् ।
तदेभिः कारणैस्सर्वैर्महद्भि र्धर्मसंहितैः ॥ २८
शासनं तव यद्युक्तं तद्भवा ननुमन्यताम् ।
सर्वथा धर्म इत्येव द्रष्टव्य स्तव निग्रहः ॥ २९
वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यता ।
शक्यं त्वयाऽपि तत्कार्यं धर्म मेवानुपश्यता ॥ ३०

श्रूयेते मनुना गीतौ श्लोकौ चारित्रवत्सलौ ।
गृहीतौ धर्मकुशलै स्तत्तथा चरितं हरे ! ॥ ३१
"राजाभि र्धृतदण्डा स्तु कृत्वा पापानि मानवाः ।
निर्मला स्स्वर्गं मायान्ति सन्त स्सुकृतिनो यथा ॥ ३२
शासना द्वा विमोक्षा द्वा स्तेनः स्तेया द्विमुच्यते ।
राजा त्वशासन्नँ ल्पापस्य तदवाप्नोति किल्बिषम् ॥" ३३
आर्येण मम मान्धात्रा व्यसनं घोर मीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ३४
अन्यै रपि कृतं पापं प्रमत्तै र्वसुधाधिपैः ।
प्रायश्चित्तंच कुर्वन्ति तेन तच्छाम्यते रजः ॥ ३५
तदलं परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल ! न वयं स्ववशे स्थिताः ॥ ३६
शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव ! ।
यच्छ्रुत्वा हेतुमद्वीर ! न मन्युं कर्तु मर्हसि ॥ ३७
नमे तत्र मनस्तापो न मन्यु र्हरियूथप ! ।
वागुराभि श्च पाशै श्च कूटै श्च विविधै र्नराः ॥ ३८
प्रतिच्छन्नाश्च दृश्या श्च गृह्णन्ति सुबहून्मृगान् ।
प्रधावितान्वा वित्रस्ता न्विसृष्टां श्चापि निष्ठितान् ॥ ३९
प्रमत्ता नप्रमत्ता न्वा नरा मांसार्थिनो भृशम् ।
विध्यन्ति विमुखां श्चापि नच दोषोऽत्र विद्यते ॥ ४०
यान्ति राजर्षय श्चात्र मृगयां धर्मकोविदाः ।
तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ! ॥ ४१

अयुध्यन्प्रतियुध्यन्वा यस्मा च्छाखामृगो ह्यसि ।
दुर्लभस्यच धर्मस्य जीवितस्य शुभस्यच ॥ ४२
राजानो वानरश्रेष्ठ ! प्रदातारो न संशयः ।
तान्नहिंस्या न चाक्रोशे न्नाक्षिपे न्नाप्रियं वदेत् ॥ ४३
देवा मानुषरूपेण चरन्त्येते महीतले ।
त्वं तु धर्म मविज्ञाय केवलं रोष मास्थितः ॥ ४४
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ।"
एव मुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ॥ ४५
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः ।
प्रत्युवाच ततो रामं प्राञ्जलि र्वानरेश्वरः ॥ ४६
"यत्त्वमात्थ नरश्रेष्ठ ! तदेवं नात्र संशयः ।
प्रतिवक्तुं प्रकृष्टे हि नाप्रकृष्ट स्तु शक्नुयात् ॥ ४७
तदयुक्तं मया पूर्वं प्रमादा दुक्त मप्रियम् ।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ ४८
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धि रव्यया ॥ ४९
मा मप्यूर्वगतंधर्मार्मृद्व्यतिक्रान्तपुरस्कृतम् ।
धर्मसंहितया वाचा धर्मज्ञ ! परिपालय ॥ ५०
बाष्पसंरुद्धकण्ठस्तु वाली सार्धरव श्शनैः ।
उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः ॥ ५१
न त्वात्मान महं शोचे नतारां नच बान्धवान् ।
यथा पुत्रं गुणज्येष्ठ मङ्गदं कनकाङ्गदम् ॥ ५२

स ममादर्शना दीनो बाल्यात्प्रभृति लालितः ।
तटाक इव पीताम्बु. रुपशोषं गमिष्यति ॥ ५३
बाल श्चाकृतबुद्धि श्च एकपुत्र श्च मे प्रियः ।
तारेयो राम ! भवता रक्षणीयो महाबलः ॥ ५४
सुग्रीवे चाङ्गदे चैव विधत्स्व मति मुत्तमाम् ।
त्वं हि शास्ताच गोप्ताच कार्याकार्यविधौ स्थितः ॥ ५५
या ते नरपते ! वृत्ति र्भरते लक्ष्मणे च या ।
सुग्रीवे चाङ्गदे राजं ! स्तां त्व माधातु मर्हसि ॥ ५६
मदोषकृतदोषां तां यथा तारां तपस्विनीम् ।
सुग्रीवो नानुमन्येत तथाऽवस्थातु मर्हसि ॥ ५७
त्वया ह्यनुगृहीतेन राज्यं शक्य मुपासितुम् ।
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ५८
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ।
त्वतोऽहं वध माकाङ्क्ष न्वार्यमाणोऽपि तारया ॥ ५९
सुग्रीवेण सहभ्राता द्वन्द्वयुद्ध मुपागतः ।"
इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ॥ ६०
स त मा श्वासय द्रामो वालिनं व्यक्तदर्शनम् ।
सामसंपन्नया वाचा धर्मतत्त्वार्थयुक्तया ॥ ६१
न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम ! ।
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ॥ ६२
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ।
दण्ड्ये यः पातये द्दण्डं दण्ड्यो यश्चापि दण्ड्यते ॥ ६३

कार्यकारणसिद्धार्थौ वुभौ तौ नावसीदतः ।
तद्भुवा न्दण्डसंयोगा दस्मा द्विगतकल्मषः ॥ ६४
गत स्त्वां प्रकृतिं धर्म्यां धर्मदृष्टेन वर्त्मना ।
त्यज शोकंच मोहं च भयंच हृदये स्थितम् ॥ ६५
त्वया विधानं हर्यक्ष! नशक्य मति वर्तितुम् । उत्य
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर! ॥ ६६
तथा वर्तेत सुग्रीवे मयि चापि नसंशयः ।"
स तस्य वाक्यं मधुरं महात्मन स्समाहितं धर्मपथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो वचस्सुयुक्तं निजगाद वानरः ॥ ६७
शराभितप्तेन विचेतसा मया प्रदूषित स्त्वं यदजानता प्रभो! ।
इदं महेन्द्रोपमभीमविक्रम! प्रसादित स्त्वं क्षम मे नरेश्वर! ॥ ६८

इति श्रीमत्किष्किन्धाकाण्डे अष्टादशस्सर्गः ॥

॥ एकोनविंशस्सर्गः ॥

स वानरमहाराज श्शयान श्शरविक्षतः ।
प्रत्युक्तो हेतुमद्वाक्यै र्नोत्तरं प्रत्यपद्यत ॥ १
अश्मभिः प्रविभिन्नाङ्गः पादपै राहतो भृशम् ।
रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ॥ २
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे ।
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ ३
सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तु स्सुदारुणम् ।
निष्पपात भृशं त्रस्ता विविधा द्विरिगह्वरात् ॥ ४

येत्वङ्गदपरीवारा वानरा भीमविक्रमाः ।
ते सकार्मुक मालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ ५
सा ददर्श तत स्त्रस्तान्हरीनाप ततोभृशम् ।
यूथादिव परिभ्रष्टा न्मृगा न्निहतयूथपान् ॥ ६
तानुवाच समासाद्य दुःखिता न्दुःखिता सती ।
रामवित्रासितां त्सर्वाननुबद्धानिवेषुभिः ॥ ७
"वानरा! राजसिंहस्य यस्य यूयं पुरस्सराः ।
तं विहाय सुसंत्रस्ताः कस्मा द्व्यथ दुर्गताः ॥ ८
राज्यहेतो स्स चेद्भ्राता भ्रात्रा रौद्रेण पातितः ।
रामेण प्रहितै रौद्रैर्मार्गणै र्दूरपातिभिः ॥ ९
कपिपत्न्या वचश्श्रुत्वा कपयः कामरूपिणः ।
प्राप्तकाल मविक्लिष्ट मूचुर्वचन मङ्गनाम् ॥ १०
"जीवपुत्रे! निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् ।
अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ ११
क्षिप्तान् वृक्षां त्समाविध्य विपुलाश्च शिलास्तथा ।
वाली वज्रसमैर्बाणै रामेण विनिपातितः ॥ १२
अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् ।
अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ॥ १३
रक्ष्यतां नगरद्वार मङ्गदश्चाभिषिच्यताम् ।
पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥ १४
अथवाऽनुचितं स्थान मिह ते रुचिरानने! ।
आविशन्तिहि दुर्गाणि क्षिप्रमन्यानि वानराः ॥ १५

अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः ।
लुब्धेभ्यो विप्रयुक्तेभ्य स्तेभ्यो नस्तुमुलं भयम् ॥" १६
अल्पान्तरगतानां तु श्रुत्वा वचन मङ्गना ।
आत्मनः प्रतिरूपं सा वभाषे चारुहासिनी ॥ १७
" पुत्रेण मम किं कार्यं किं राज्येन किमात्मना ।
कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति ॥ १८
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ।
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥" १९
एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता ।
शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥ २०
आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ।
हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ २१
क्षेप्तारं पर्वतेन्द्राणां वज्रानामिव वासवम् ।
महावातसमाविष्टं महामेघौघनिस्वनम् ॥ २२
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् ।
नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥ २३
शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ।
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ २४
नागहेतो स्सुपर्णेन चैत्य मुन्मथितं यथा ।
अवष्टभ्यच तिष्ठन्तं ददर्श धनुरुत्तमम् ॥ २५
रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ।
ज्ञातीत्य समासाद्य भर्तारं निहतं रणे ॥ २६

समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ।
सुग्रीव पुनरुत्थाय 'आर्यपु 'त्रेति शोचति ॥ २७
रुरोद सा पतिं दृष्ट्वा संवृतं मृत्युदामभिः ।
तामवेक्ष्यतु सुग्रीवः क्रोशन्तीं कुररी मिव ॥ २८
विषाद मगमत्कष्टं दृष्ट्वा चाक्रन्द मागतम् ॥

इति श्रीमत्किष्किन्धाकाण्डे एकोनविंशस्सर्गः ॥

॥ विंशस्सर्गः ॥

रामचापविसृष्टेन शरेणान्तकरेणतम् ।
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ १
सासमासाद्य भर्तारं पर्यष्वजत भामिनी ।
इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ २
वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा ।
तारा तरुमिवोन्मूलं पर्यदेवय दातुरा ॥ ३
"रणे दारुण विक्रान्त प्रवीर! प्लवतां वर! ।
किदानीमपुरोभागा मद्यत्वं नाभिभाषसे ॥ ४
उत्तिष्ठ हरिशार्दूल! भजस्व शयनोत्तमम् ।
नैवंविधा शेरते हि भूमौ नृपतिसत्तमाः ॥ ५
अतीव खलु ते कान्ता वसुधा वसुधाधिप! ।
गतासुरपि यां गात्रै र्मां विहाय निषेवसे ॥ ६
व्यक्तमन्या त्वया वीर! धर्मतस्संप्रवर्तिता ।
किष्किन्धेव पुरीरम्या स्वर्गमार्गे विनिर्मिता ॥ ७

यान्यस्माभि स्त्वया सार्धं वनेषु मधुगन्धिषु ।
विहृतानि त्वया काले तेषा मुपरमः कृतः ॥ ८
निरानन्दा निराशाऽहं निमग्ना शोकसागरे ।
त्वयि पञ्चत्व मापन्ने महायूथपयूथपे ॥ ९
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् ।
यन्नशोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ १०
सुग्रीवस्य त्वया भार्या हृता सचविवासितः ।
यत्तुतस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ! ॥ ११
निःश्रेयसपरामोहात्त्वया चाहं विगर्हिता ।
यैषाऽब्रुवं हितं वाक्यं वानरेन्द्र ! हितैषिणी ॥ १२
रूपयौवनदृप्तानां दक्षिणानां च मानद ! ।
नून मप्सरसा मार्य ! चित्तानि प्रमथिष्यसि ॥ १३
कालो निस्संशयो नूनं जीवितान्तकरस्तव ।
बलाद्येनावपन्नोऽसि सुग्रीवस्यावशोवशम् ॥ १४
वैधव्यं शोकसंतापं कृपणं कृपणासती ।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ १५
लालितश्चाङ्गदो वीर स्सुकुमार स्सुखोचितः ।
वत्स्यते का मवस्थां मे पितृव्ये क्रोधमूर्छिते ! ॥" १६
"कुरुष्व पितरं पुत्र ! सुदृष्टं धर्मवत्सलम् ।
दुर्लभं दर्शनं वत्स ! तव तस्य भविष्यति ॥" १७
सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।
इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ १८

"समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च ।
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १९
रामेण हि महत्कर्म कृतंत्वामभिनिघ्नता ।
आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥" २०
"सकामो भव सुग्रीव ! रुमां त्वं प्रतिपत्स्यसे ।
भुङ्क्ष्व राज्य मनुद्विग्नश्शत्रोर्भ्रातरिपुस्तव ॥" २१
किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे ।
इमाः पश्य वरारोहीर्भार्यास्ते वानरेश्वर ! ॥" २२
तस्या विलपितं श्रुत्वा वानर्य स्सर्वतश्च ताः ।
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ॥ २३
"किं मङ्गदं साङ्गदवीरबाहो ! विहाय यास्यद्धिचिरंप्रवासम् ।
न युक्तमेवंगुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र ! गन्तुम् ॥ २४
किमप्रियं ते प्रिय ! चारुवेष ! मया कृतं नाथ ! सुतेन वा ते ।
सहाङ्गदां मां प्रविहाय वीर ! यत्प्रस्थितो दीर्घ मितः प्रवासम् ॥
यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्या त्तव दीर्घबाहो ।
क्षमस्व मे तद्धरिवंशनाथ ! व्रजामि मूर्ध्ना तव वीर ! पादौ ॥ २६
तथा तु तारा करुणं रुदन्ती भर्तुस्समीपे सह वानरीभिः ।
व्यवस्यत प्रायमुपोपवेष्टु मनिन्द्यवर्णा भुवि यत्र वाली ॥ २७

इति श्रीमत्किष्किन्धाकाण्डे विंशस्सर्गः ॥

॥ एकविंशस्सर्गः ॥

ततो निपतितां तारां च्युतां ताराभिवाम्बरात् ।
शनै राश्वासयामास हनूमान्हरियूथपः ॥ १

"गुणदोषकृतं जन्तु स्वकर्मफलहेतुकम् ।
अव्यग्र स्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ २
शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे ।
कस्य को वाऽनुशोच्योऽस्ति देहेऽस्मि न्बुद्बुदोपमे ॥ ३
अङ्गद स्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ ४
जानास्यनियता मेवं भूताना मागतिं गतिम् ।
तस्मा च्छुभं हि कर्तव्यं पण्डितेनेह लौकिकम् ॥ ५
यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च ।
वर्तयन्ति कृतांशानि सोऽयं दिष्टान्त मागतः ॥ ६
यदयं न्यायदृष्टार्थ स्सामदानक्षमापरः ।
गतो धर्मजितां भूमिं नैनं शोचितु मर्हसि ॥ ७
सर्वेहि हरिशार्दूलाः पुत्र श्चायं तवाङ्गदः ।
इदं हर्यृक्षराज्यं च त्वत्सनाथ मनिन्दिते ! ॥ ८
ता विमौ शोकसंतापौ शनैः प्रेम्न भामिनि ! ।
त्वया परिगृहीतोऽय मङ्गद श्शास्तु मेदिनीम् ॥ ९
सन्तति श्च यथा दृष्टा कृत्यं यच्चापि सांप्रतम् ।
राज्ञ स्तत्क्रियतां सर्वं मेष कालस्य निश्चयः ॥ १०
संस्कार्यो हरिराज श्च अङ्गद श्चाभिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यन्ती शान्ति मेष्यसि ॥ ११
सा तस्य वचनं श्रुत्वा भर्तुर्व्यसनपीडिता ।
अब्रवी दुत्तरं तारा हनूमन्त मवस्थितम् ॥ १२

"अङ्गदप्रतिरूपाणां पुत्राणा मेकत श्शतम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३

न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा ।
पितृव्य स्तस्य सुग्रीव स्सर्वकार्येष्वनन्तरः ॥ १४

न ह्येषा बुद्धि रास्थेया हनूम! न्नङ्गदं प्रति ।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम! ॥ १५

न हि मम हरिराजसंश्रयात्क्षमतर मस्ति परत्र चेह वा ।
अभिमुखहत वीरसेवितं शयन मिदं मम सेवितुं क्षमम् ॥" १६

इति श्रीमत्किष्किन्धाकाण्डे एकविंशस्सर्गः ॥

॥ द्वाविंशस्सर्गः ॥

वीक्षमाणस्तु मन्दासु स्सर्वतो मन्द मुच्छ्वसन् ।
आदावेव तु सुग्रीवं ददर्श वालजाग्रतः ॥ १
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः ।
आभाष्य व्यक्तया वाचा सस्नेह मिद मब्रवीत् ॥ २
सुग्रीव! दोषेण नमां गन्तु मर्हसि किल्बिषात् ।
कृष्यमाणं भविष्येण बुद्धिमोहेन मांबलात् ॥ ३
युगपद्विहितं तात! न मन्ये सुख मावयोः ।
सौहार्दं भ्रातृयुक्तं हि तदिदं तात! नान्यथा ॥ ४
प्रतिपद्य त्व मद्यैव राज्य मेषां वनौकसाम् ।
मा मप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ५

जीवितं च हि राज्यं च श्रियं च विपुला मिमाम् ।
प्रजहाम्येष वैतूर्णं महच्चागर्हितं यशः ॥ ६
अस्यां त्वह मवस्थायां वीर! वक्ष्यामि यद्वचः ।
यद्यप्यसुकरं राज! न्कर्तुमेव तदर्हसि ॥ ७
सुखार्हं सुखसंवृद्धं बालमेन मबालिशम् ।
बाष्पपूर्णमुखं पश्य भूमौ पतित मङ्गदम् ॥ ८
ममप्राणैः प्रियतरं पुत्रं पुत्र मिवौरसम् ।
मया हीन महीनार्थं सर्वतः परिपालय ॥ ९
त्व मेवास्य हि दाता च परित्राता च सर्वतः ।
भयेष्वभयद श्चैव यथाऽहं प्लवगेश्वर! ॥ १०
एष तारात्मजः श्रीमां स्त्वया तुल्यपराक्रमः ।
रक्षसां तु वधे तेषा मग्रत स्ते भविष्यति ॥ ११
अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे ।
करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ॥ १२
सुषेणदुहिता चेय मर्थसूक्ष्मविनिश्चये ।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १३
यदेषा साध्विति ब्रूया त्कार्यं तन्मुक्तसंशयम् ।
नहि तारामतं किंचि दन्यथा परिवर्तते ॥ १४
राघवस्य च ते कार्यं कर्तव्य मविशङ्कया ।
स्यादधर्मो ह्यकरणे त्वां च हिंस्या द्विमानितः ॥ १५
इमां च माला माधत्स्व दिव्यां सुग्रीव! काञ्चनीम् ।
उदारा श्रीस्थिताह्यस्यां संप्रजह्या न्मृते मयि ॥" १६

इत्येव मुक्त स्सुग्रीवो वालिना भ्रातृसौहृदात् ।
हर्षं त्यक्त्वा पुन र्दीनो ग्रहग्रस्त इवोडुराट् ॥ १७
तद्वालिवचना च्छान्तः कुर्व न्युक्त मतन्द्रितः ।
जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ १८
तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम् ।
संसिद्धः प्रेत्यभावाय स्नेहा दङ्गद मब्रवीत् ॥ १९
"देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।
सुखदुःखसहः काले सुग्रीववशगो भव ॥ २०
यथा हि त्वं महाबाहो! लालित स्सततं मया ।
स तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ २१
मास्यामित्रैर्गतं गच्छे र्मा शत्रुभि रिरिन्दम! ।
भर्तु रर्थपरो दान्त स्सुग्रीववशगो भव ॥ २२
न चातिप्रणयः कार्यः कर्तव्योऽप्रणय श्च ते ।
उभयं हि महादोषं तस्मा दन्तरदृग्भव ॥" २३
इत्युक्त्वाऽथ विवृत्ताक्ष श्शरसंपीडितो भृशम् ।
विवृतै र्दशनै र्भीमै र्बभूवोत्क्रान्तजीवितः ॥ २४
ततो विचुक्रुशु स्तत्रवानरा हरियूथपाः ।
परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः ॥ २५
"किष्किन्धा ह्यद्य शून्याऽसी त्स्वर्गते वानराधिपे ।
उद्यानानि च शून्यानि पर्वताः काननानिच ॥ २६
हते प्लवगशार्दूले निष्प्रभा! वानराः कृताः ।
यस्य वेगेन महता काननानि वनानिच ॥ २७

पुष्पौघेनानुबध्यन्ते करिष्यति तदद्यकः ।
येन दत्तं मह द्युद्धं गन्धर्वस्य महात्मनः ॥ २८
गोलभस्य महाबाहोर्दश वर्षाणि पञ्चच ।
नैव रात्रौ न दिवसे तद्युद्ध मुपशाम्यति ॥ २९
तत स्तु षोडशे वर्षे गोलभो विनिपातितः ।
हत्वा तं दुर्विनीतं तु वाली दंष्ट्रा कराळवान् ॥ ३०
सर्वाभयकरोऽस्माकं कथ मेष निपातितः ।"
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमा स्तत्र न शर्म लेभिरे ।
वनेचरा सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥ ३१
ततस्तु तारा व्यसनार्णवाप्लुतौ मृतस्य भर्तुर्वदनं समीक्ष्य सा ।
जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥

इति श्रीमत्किष्किन्धाकाण्डे द्वाविंशस्सर्गः ॥

॥ त्रयोविंशस्सर्गः ॥

ततस्समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ १
"शेषेत्वं विषमे दुःख मकृत्वा वचनं मम ।
उपलोपचिते वीर! सुदुःखे वसुधातले ॥ २
मत्तः प्रियतरा नूनं वानरेन्द्र! मही तव ।
शेषे हि तां परिष्वज्य मांच न प्रतिभाषसे ॥ ३
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ।
सुग्रीव एव विक्रान्तो वीर! साहसिक प्रिय! ॥ ४

ऋक्षवानरमुख्या स्त्वां बलिनः पर्युपासते ।
एषां विलपितं कृच्छ्रं मङ्गदस्यच शोचतः ॥ ५
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ।
इदंतच्छूरशयनं यत्र शेषे हतो युधि ॥ ६
शायिता निहता यत्र त्वयैव रिपवः पुरा ।
विशुद्धसत्त्वाभिजन ! प्रिययुद्ध ! मम प्रिय ! ॥ ७
मामनाथां विहायैकां गतस्त्वमसि मानद ! ।
शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥ ८
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ।
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥ ९
अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ।
अश्मसारमयं नून मिदं मे हृदयं दृढम् ॥ १०
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ।
सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः ॥ ११
आहवे च पराक्रान्त श्शूरः पञ्चत्व मागतः ।
पतिहीनातु या नारी कामं भवतु पुत्रिणी ॥ १२
धनधान्यै स्सुपूर्णाऽपि विधवेत्युच्यते जनैः ।
स्वगात्रप्रभवे वीर ! शेषे रुधिरमण्डले ॥ १३
क्रिमिरागपरिस्तोमे त्व मात्मशयने यथा ।
रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥ १४
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ! ।
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मि न्नतिदारुणे ॥ १५

यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ।
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ॥ १६
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्व मागते ।"
उद्बर्ह शरं नीलस्तस्य गात्रगतं तदा ॥ १७
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ।
तस्य निष्कृष्यमाणस्य बाणस्यच बभौ द्युतिः ॥ १८
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ।
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ॥ १९
ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ।
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ॥ २०
अश्रुनेत्रजैरशूरं सिषेचास्रसमाहतम् । से
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥ २१
उवाच तारा पिङ्गाक्षं पुत्र मङ्गदमङ्गना ।
"अवस्थां पश्चिमां पश्य पितुः पुत्र! सुदारुणाम् ॥ २२
संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ।
बालसूर्योदयतनुं प्रयान्तं यमसादनम् ॥ २३
अभिवादय राजानं पितरं पुत्र! मानदम् ।"
एव मुक्तस्समुत्थाय जग्राह चरणौ पितुः ॥ २४
भुजाभ्यां पीनवृत्ताभ्या 'मङ्गदोऽह' मिति ब्रुवन् ।
"अभिवादयमानं त्वा मङ्गदं त्वं यथा पुरा ॥ २५
'दीर्घायुर्भव पु'त्रेति किमर्थं नाभिभाषसे ।
अहं पुत्रसहाया त्वा मुपासे गतचेतनम् ॥ २६

सिंहेन निहतं सद्यो गौस्सवत्सेव गोवृषम् ।
इङ्गा संग्रामयज्ञेन रामप्रहरणाम्भसि ॥ २७
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ।
या दत्ता देवराजेन तव तुष्टेन संयुगे ॥ २८
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ।
राजश्री र्नजहाति त्वां गतासु मपि मानद ! ॥ २९
सूर्यस्यावर्तमानस्य शैलराज मिव प्रभा ।
न मे वचः पथ्य मिदं त्वया कृतं नचास्मि शक्ता विनिवारणे तव ।
हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥"

इति श्रीमत्किष्किन्धाकाण्डे त्रयोविंशतितमस्सर्गः ॥

॥ चतुर्विंशस्सर्गः ॥

तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन ।
पश्यंस्तदा बाल्यनुज स्तरस्वी भ्रातु र्वधेनाप्रतिमेन तेपे ॥ १
स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ।
जगाम रामस्य शनै स्समीपं भृत्यै र्वृत स्संपरिदृश्यमानः ॥ २
स तं समासाद्य गृहीतचाप मुदात्त माशीविषतुल्यबाणम् ।
यशस्विनं लक्ष्मणलक्षिताङ्ग मवस्थितं राघव मित्युवाच ॥ ३
"यथा प्रतिज्ञात मिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ।
ममाद्य भोगेषु नरेन्द्रपुत्र ! मनो निवृत्तं सह जीवितेन ॥ ४
अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते ।
हतेऽग्रजेसंशयितेऽङ्गदे च न राम ! राज्ये रमते मनो मे ॥ ५

क्रोधादमर्षा दतिविप्रधर्षा द्भ्रातु र्वधो मेऽनुमतः पुरस्तात् ।
हते त्विदानीं हरियूथपेऽस्मिं स्सुतीव्र मिक्ष्वाकुकुमार! तप्स्ये ॥ ६
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवास श्चिर मृश्यमूके ।
यथा तथा वर्तयत स्स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ॥ ७
'न त्वां जिघांसामि च'रेतियन्मामयं महात्मा मतिमा नुवाच ।
तस्यैव तद्राम! वचोऽनुरूप मिदं पुनः कर्मच मेऽनुरूपम् ॥ ८
भ्राता कथं नाम महागुणस्य भ्रातु र्वधं राघव! रोचयेत!
राज्यस्य दुःखस्य च वीर! सारं नचिन्तयन्कामपुरस्कृत स्सन् ॥ ९
वधो हि मे मतो नासौ त्स्वमाहात्म्याव्यतिक्रमात् ।
ममाऽसौ द्वुद्धिदौरात्म्या त्प्राणहारी व्यतिक्रमः ॥ १०
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन् ।
सान्त्वयित्वा त्वनेनोक्तो नपुनः कर्तुमर्हसि ॥ ११
भ्रातृत्वमार्यभाव श्च धर्म श्चानेन रक्षितः ।
मया क्रोध श्च कामश्च कपित्वंच प्रदर्शितम् ॥ १२
अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मान मिमं नरेन्द्र! भ्रातु र्वधात्त्वाट्टवधादिवेन्द्रः ॥
पाप्मान मिन्द्रस्य महीं जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च ।
को नाम पाप्मान मिमं क्षमेत शाखामृगस्य प्रतिपत्तु मिच्छन् ॥ १४
नार्हामि सम्मान मिमं प्रजानां न यौवराज्यं कुतएव राज्यम् ।
अधर्मयुक्तं कुलनाशयुक्त मेवंविधं राघव! कर्म कृत्वा ॥ १५
पापस्य कर्ता ऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव ।
शोको महान्मामभिवर्ततेऽयं वृष्टे र्यथा निम्न मिवाम्बुवेगः ॥ १६

सोदर्यघातापरगात्रवाल स्सन्तापहस्ताक्षिशिरोविषाणः ।
एनोमयो मा मभिहन्ति हस्ती द्वयो नदीकूलमिव प्रवृद्धः ॥ १७
अंहो बतेदं नृवरा विषह्यं निवर्तते मे हृदिसाधु वृत्तम् ।
विवर्णमम्लौ परितप्यमानं किट्टं यथा राघव ! जातरूपम् ॥ १८
महाबलानां हरियूथपाना मिदं कुलं राघव ! मन्निमित्तम् ।
अस्याङ्गदस्यापि च शोकतापा दर्धं स्थितप्राण मितीव मन्ये ॥
सुत स्सुलभ्यस्सुजन स्सुवंश्यः कुत स्सुपुत्र स्सदृशोऽङ्गदेन ।
नचापि विद्येत स वीर ! देशो यस्मिन्भवेत्सोदरसन्निकर्षः ॥ २०
यद्यङ्गदो वीर ! वराह ! जीवेज्जीवेच्च माता परिपालनार्थम् ।
विना तु पुत्रं परितापदीना तारा नजीवेदिति निश्चितं मे ॥ २१
सोऽहं प्रवेक्ष्याम्यतिदीप्त मग्निं भ्रात्रा च पुत्रेण च सख्य मिच्छन् ।
इमे विचेष्यन्ति हरिप्रवीरा स्सीतां निदेशे तव वर्तमानाः ॥ २२
कृत्स्नंतु ते सेत्स्यति कार्य मेतन्म य्यागतेते मनुजेन्द्रपुत्र !
कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम् ॥" २३
इत्येव मार्तस्य रघुप्रवीर श्श्रुत्वा वचो वाल्यनुजस्य तस्य ।
संजातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव ॥ २४
तस्मिन् क्षणेऽभीक्ष्ण मवेक्षमाणः क्षितिक्षमावा न्भुवनस्य गोप्ता ।
रामो रुदन्तीं व्यसने निमग्नां समुत्सुक स्सोऽथ ददर्श ताराम् ॥२५
तां चारुनेत्रां कपिसिंहनाथं पतिंसमाश्लिष्य तदा शयानाम् ।
उत्थापयामासु रदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम् ॥ २६
सा विस्फुरन्ती परिरभ्यमाणा भर्तु स्सकाशा दपनीयमाना ।
ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ २७

सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा ।
अदृष्टपूर्वंपुरुषप्रधान 'मयं स काकुत्स्थ' इति प्रजज्ञे ॥ २८
तस्येन्द्रकल्पस्यदुरासदस्य महानुभावस्य समीप मार्या ।
आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ २९
सा तं समासाद्य विशुद्धसत्त्वा शोकेन संभ्रान्तशरीरभावा ।
मनस्विनी वाक्य मुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ ३०
"त्व मप्रमेय श्च दुरासद श्च जितेन्द्रिय श्चोत्तम धार्मिक श्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाक्षः ॥ ३१
त्व मात्तबाणासन बाणपाणि र्महाबल स्संहननोपपन्नः ।
मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ ३२
येनैकबाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन ।
हता गमिष्यामि समीप मस्य न मा मृते राम! रमेत वाली ॥ ३३
स्वर्गेऽपि पद्मामलपत्रनेत्रस्समेत्य संप्रेक्ष्यच मा मपश्यन् ।
न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ॥ ३४
स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर! वाली ।
रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ ३५
त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः ।
तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ ३६
यच्चापि मन्येत भवा न्महात्मा स्त्रीघातदोषोनभवेत्तु मह्यम् ।
आत्मेय मस्येति च मां जहि त्वं नस्त्रीवधस्स्यान्मनुजेन्द्रपुत्र! ॥ ३७
शास्त्रप्रयोगाद्विविधा च वेदा दात्मा ह्यनन्यः पुरुषस्य दारः ।
दारप्रदाना न्नहि दानमन्य त्प्रदृश्यते ज्ञानवतां हि लोके ॥ ३८

त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर ! ।
अनेन दानेन नलप्स्यसे त्व मधर्मयोगं मम वीरघातात् ॥ ३९
आर्तामनाथा मपनीयमाना मेवंविधा महंसि मां निहन्तुम् ।
अहंहि मातङ्गविलासगामिना प्लवङ्गमाना मृषभेण धीमता ॥ ४०
विना वराहोत्तमहेममालिना चिरं नशक्ष्यामि नरेन्द्र ! जीवितुम् ।
"इत्येव मुक्तस्तु विमुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ ४१
"मा वीरभार्ये ! विमतिं कुरुष्व लोकोहि सर्वो विहितो विधात्रा ।
तं चैव सर्वं सुखदुःखयोगं लोकोऽत्रवीत्तेन कृतं विधात्रा ॥ ४२
त्रयोहि लोका विहितं विधानं नातिक्रमन्ते वशगा हितस्य ।
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ॥ ४३
धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति ।"
आश्वासिता तेनतु राघवेण प्रभावयुक्तेन परन्तपेन ॥ ४४
सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥

इति श्रीमत्किष्किन्धाकाण्डे चतुर्विंशस्सर्गः ॥

॥ पञ्चविंशस्सर्गः ॥

सुग्रीवं चैव तारांच साङ्गदं सहलक्ष्मणः ।
समानशोकः काकुत्स्थस्सान्त्वयन्निद मब्रवीत् ॥ १
"नशोकपरितापेन श्रेयसा युज्यते मृतः ।
यदत्रानन्तरं कार्यं तत्समाधातु महंथ ॥ २
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।
न काला दुत्तरं किंचि त्कर्म शक्य मुपासितुम् ॥ ३

नियतिः कारणं लोके नियतिः कर्म साधनम् ।
नियति स्सर्वभूतानां नियोगेष्विह कारणम् ॥ ४
न कर्ता कस्यचि त्कश्चि न्नियोगे चापि नेश्वरः ।
स्वभावे वर्तते लोक स्तस्य कालः परायणम् ॥ ५
नकालः काल मत्येति नकालः परिहीयते ।
स्वभावंच समासाद्य नकश्चि दतिवर्तते ॥ ६
नकालस्यास्ति बन्धुत्वं न हेतु र्नपराक्रमः ।
नमित्रज्ञातिसंबन्धः कारणं नात्मनो वशः ॥ ७
किंतु कालपरीणामो द्रष्टव्य स्साधु पश्यता ।
धर्म श्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ ८
इत स्त्वां प्रकृतिं वाली गतःप्राप्तः क्रियाफलम् ।
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ॥ ९
स्वधर्मस्य च संयोगा ज्जित स्तेन महात्मना ।
स्वर्गः परिगृहीत श्च प्राणा नपरिरक्षता ॥ १०
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ।
तदलं परितापेन प्राप्तकाल मुपास्यताम् ॥" ११
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ १२
"कुरु त्व मस्य सुग्रीव! प्रेतकार्यं मनन्तरम् ।
ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति ॥ १३
समाज्ञापय काष्ठानि शुष्कानिच बहूनिच ।
चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ॥ १४

समाश्वासय चैनं त्व मङ्गदं दीनचेतसम् ।
माभू र्बालिशबुद्धि स्त्वं त्वदधीनमिदं पुरम् ॥ १५
अङ्गद स्त्वानयेन्माल्यं वस्त्राणि विविधानि च ।
घृतं तैल मथो गन्धान्यत्रात्र समनन्तरम् ॥ १६
त्वं तार! शिबिकां शीघ्रमादायागच्छ संभ्रमात् ।
त्वरा गुणवती युक्ता ह्यस्मि न्काले विशेषतः ॥ १७
सज्जीभवन्तु प्लवगा श्शिबिका वहनोचिताः ।
समर्था बलिन श्चैव निर्हरिष्यन्ति वालिनम् ॥" १८
एव मुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः ।
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ १९
लक्ष्मणस्य वच श्श्रुत्वा तार स्संभ्रान्तमानसः ।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ २०
आदाय शिबिकां तार स्ततु पर्यपतत्पुनः ।
वानरै रूह्यमनां तां शूरै रुद्वहनोचितैः ॥ २१
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् ।
पक्षिकर्मभि राचित्रां द्रुमकर्मविभूषिताम् ॥ २२
आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः ।
विमानमिव सिद्धानां जालवातायनान्विताम् ॥ २३
सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ।
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ॥ २४
वराभरणहारैश्च चित्रमाल्योपशोभिताम् ।
गुहागहनसंच्छन्नां रक्तचन्दनरूषिताम् ॥ २५

पुष्पौघै स्समभिच्छन्नां पद्ममालाभिरेवच ।
तरुणादित्यवर्णाभि र्भ्राजमानाभि रावृताम् ॥ २६
ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मण मब्रवीत् ।
" क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥ २७
ततो वालिन मुद्यम्य सुग्रीव श्शिबिकां तदा ।
आरोपयत विक्रोश न्नङ्गदेन सहैव तु ॥ २८
आरोप्य शिबिकां चैव वालिनं गतजीवितम् ।
अलंकारै श्च विविधै र्माल्यै र्वस्त्रै श्च भूषितम् ॥ २९
आज्ञापय त्तदा राजा सुग्रीवः प्लवगेश्वरः ।
और्ध्वदैहिक मार्यस्य क्रियता मनुरूपतः ॥ ३०
विश्राणयन्तो रत्नानि विविधानि बहून्यपि ।
अग्रतः प्लवगायान्तु शिबिका समनन्तरम् ॥ ३१
राज्ञा मृद्धिविशेषा हि दृश्यन्ते भुवियादृशाः ।
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् ॥ ३२
अङ्गदं परिगृह्याऽशु तारप्रभृतयस्तदा ।
क्रोशन्तः प्रययु स्सर्वे वानराहतबान्धवाः ॥ ३३
ततः प्रणिहिता स्सर्वा वानर्योऽस्य वशानुगाः ।
चुक्रुशु ' वीर 'वीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ ३४
ताराप्रभृतय स्सर्वा वानर्यो हतयूथपाः ।
अनुजग्मु र्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ ३५
तासां रुदितशब्देन वानरीणां वनान्तरे ।
वनानि गिरय स्सर्वे विक्रोशन्तीव सर्वतः ॥ ३६

पुलिने गिरिनद्या स्तु विविक्ते जलसंवृते ।
चितां चक्रु स्सुबहवो वानरा इशोककर्शिताः ॥ ३७
अवरोप्य तत स्स्कन्धा च्छिबिकां वहनोचिताः ।
तस्थु रेकान्त माश्रित्य सर्वे शोकसमन्विताः ॥ ३८
तत स्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ।
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ ३९
"हा वानर! महाराज! हा नाथ! मम वत्सल! ।
हा महार्ह! महाबाहो! हा मम प्रिय! पश्यमाम् ॥ ४०
जनं नपश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ।
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद! ॥ ४१
अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ।
एष त्वां रामरूपेण कालः कर्षति वानर! ४२
येन स्मविधवा स्सर्वाः कृता एकेपुणा वने ।
इमास्ता स्तव राजेन्द्र! वानर्योविलभास्सदा ॥ ४३
पादै र्विकृष्ट मध्वान मागताःकिं नबुध्यसे ।
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ॥ ४४
इदानीं नेक्षसे कस्मात्सुग्रीवंप्लवगेश्वरम् ।
एतेहि सचिवा राजं स्तारत्रभृतय स्तव ॥ ४५
पुरवासी जन श्चायं परिवार्यसतेऽनघ! । विशीदति
विसर्जयैतान् प्लवगा न्यथोचित मरिन्दम! । ४६
ततः क्रीडामहेसर्वा वनेषु मदनोत्कटाः ।"
एवं विलपतीं तारां पतिशोकपरिप्लुताम् ॥ ४७

उत्थापयन्ति स्म तदा वानर्य श्शोककर्शिताः ।
सुग्रीवेण तत स्सार्धं मङ्गदःपितरं रुदन् ॥ ४८
चिता मारोपयामास शोकेनाभिहतेन्द्रियः ।
ततोऽग्निं विधिव दत्त्वा सोऽपसव्यं चकार ह ॥ ४९
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ।
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः ॥ ५०
आजग्मु रुदकं कर्तुं नदीं शीतजलां शिवाम् ।
तत स्ते सहितास्तत्र ह्युदकं स्थाप्य चाग्रतः ॥ ५१
सुग्रीवतारासहिता स्सिषिचु र्वालिने जलम् ।
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ॥ ५२
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥
ततस्तु तं वालिनमप्रधृष्यं पौरुषं प्रकाश मिश्वाकु वरेषुणा हतम् ।
प्रदीप्य दीप्ताग्नि समौजसं तदा सलक्ष्मणं राम मुपेयिवान्हरिः ॥

इति श्रीमत्किष्किन्धाकाण्डे पञ्चविंशस्सर्गः ॥

॥ षड्विंशस्सर्गः ॥

ततश्शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् ।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ १
अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।
स्थिताः प्राञ्जलयस्सर्वे पितामहमिवर्षयः ॥ २
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ।
अब्रवीत्प्राञ्जलि र्वाक्यं हनूमान्मारुतात्मजः ॥ ३

"भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो! ॥ ४
भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ ५
स्नातोऽयं विविधैर्गन्धै रौषधैश्च यथाविधि ।
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥ ६
इमां गिरिगुहां रम्या मभिगन्तुमितोऽर्हसि ।
कुरुष्व स्वामिसंबन्धं वानरां त्संप्रहर्षयन् ॥" ७
एवमुक्तो हनुमता राघवः परवीरहा ।
प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ८
चतुर्दश समास्सौम्य! ग्रामं वा यदि वा पुरम् ।
न प्रवेश्यामि हनुमन्! पितु र्निर्देश पालकः ॥ ९
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ।
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥" १०
एव मुक्त्वा हनूमन्तं रामस्सुग्रीव मब्रवीत् ।
वृत्तज्ञो वृत्तसम्पन्न मुदारबलविक्रमम् ॥ ११
"इम मप्यङ्गदं वीर! यौवराज्येऽभिषेचय ।
ज्येष्ठस्य ससुतो ज्येष्ठ स्सदृशो विक्रमेण ते ॥ १२
अङ्गदोऽय मदीनात्मा यौवराज्यस्य भाजनम् ।
पूर्वोऽयं वार्षिको मास श्श्रावण स्सलिलागमः ॥ १३
प्रवृत्ता स्सौम्य! चत्वारो मासा वार्षकसंज्ञिकाः ।
नाय मुद्योगसमयः प्रविशत्वं पुरीं शुभाम् ॥ १४

अस्मिन्वत्स्याम्यहं सौम्य! पर्वते सहलक्ष्मणः ।
इयं गिरिगुहारम्या विशाला युक्तमारुता ॥ १५
प्रभूतसलिला सौम्य! प्रभूतकमलोत्पला ।
कार्तिके समनुप्राप्ते त्वं रावणवधे यत ॥ १६
एष नस्समय स्सौम्य! प्रविशत्वं स्वमालयम् ।
अभिषिक्तस्स्वराज्येच सुहृद स्संप्रहर्षय ॥" १७
इति रामाभ्यनुज्ञात स्सुग्रीवो वानराधिपः ।
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥ १८
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ।
अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ॥ १९
ततः प्रकृतय स्सर्वा दृष्ट्वा हरिगणेश्वरम् ।
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ २०
सुग्रीवः प्रकृती स्सर्वा स्संभाष्योत्थाप्य वीर्यवान् ।
भ्रातुरन्तः पुरं सौम्यं प्रविवेश महाबलः ॥ २१
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् ।
अभ्यषिञ्चन्त सुहृद स्सहस्राक्ष मिवामराः ॥ २२
तस्य पाण्डरमाजह्रु श्छत्रं हेमपरिष्कृतम् ।
शुक्लेच वालव्यजने हेमदण्डे यशस्करे ॥ २३
तथा सर्वाणि रत्नानि सर्वबीजौषधी रपि ।
स क्षीराणां च वृक्षाणां प्ररोहान्कुसुमानिच ॥ २४
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् । णि
सुगन्धीनिच माल्यानि स्थलजान्यम्बुजानिच ॥ २५

चन्दनानिच दिव्यानि गन्धांश्च विविधान्बहून् ।
अक्षतं जातरूपंच प्रियङ्गुमधुसर्पिषी ॥ २६
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ।
समालम्भन मादाय रोचनां समनश्शिलाम् ॥ २७
आजग्मु स्तत्रमुदिता वराः कन्यास्तु षोडश ।
ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ॥ २८
रत्नै र्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ।
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ॥ २९
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ।
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ॥ ३०
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ।
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ॥ ३१
नदीनदेभ्य स्संहृत्य तीर्थेभ्य श्च समन्ततः ।
आहृत्यच समुद्रेभ्य स्सर्वेभ्यो वानरर्षभाः ॥ ३२
अपः कनककुम्भेषु निधाय विमलाश्शुभाः ।
शुभै र्वृषभशृङ्गैश्च कलशै श्चापि काञ्चनैः ॥ ३३
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।
गजो गवाक्षो गवय श्शरभो गन्धमादनः ॥ ३४
मैन्दश्च द्विविदश्चैव हनूमान्जाम्बवान्नलः ।
अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ॥ ३५
सलिलेन सहस्राक्षं वसवो वासवं यथा ।
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः ॥ ३६

प्रचुक्रुशु र्महात्मानो हृष्टा स्तत्र सहस्रशः ।
रामस्य तु वचः कुर्वं त्सुग्रीवो हरिपुङ्गवः ॥ ३७
अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यषेचयत् ।
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ॥ ३८
'साधुसा'ध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ।
रामं चैव महात्मानं लक्ष्मणंच पुनः पुनः ॥ ३९
प्रीताश्च तुष्टुवु स्सर्वे तादृशे तत्र वर्तति ।
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ॥ ४०
बभूव नगरी रम्या किष्किंधागिरिगह्वरे ।
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।
रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपोयथा ॥

इति श्रीमत्कैष्किन्धाकाण्डे षड्विंशस्सर्गः ॥

॥ सप्तविंशस्सर्गः ॥

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ १
शार्दूलमृगसंघुष्टं सिंहै र्भीमरवै र्वृतम् ।
नानागुल्मलतागूढं बहुपादपसंकुलम् । २
ऋक्षवानरगोपुच्छै र्मार्जारैश्च निषेवितम् ।
मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ ३
तस्य शैलस्य शिखरे महती मायतां गुहाम् ।
प्रत्यगृह्णत वासार्थं राम स्सौमित्रिणा सह ॥ ४

कृत्वाच समयं सौम्य सुग्रीवेन सहानघः ।
कालयुक्तं महद्वाक्य मुवाच रघुनन्दनः ॥ ५
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ।
"इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥ ६
अस्यां वसाव सौमित्रे! वर्षरात्र मरिन्दम! ।
गिरिशृङ्ग मिदं रम्य मुन्नतं पार्थिवात्मज! ॥ ७
श्वेताभिः कृष्णताम्राभि श्शिलाभि रुपशोभितम् ।
नानाधातुसमाकीर्णं हरिनिर्झरशोभितम् ॥ ८
विविधै र्वृक्षषण्डै श्च चारुचित्रलतावृतम् ॥
नानाविहगसंघुष्टं मयूररवनादितम् ॥ ९
मालतीकुन्दगुल्मै श्च सिन्धुवार कुरण्टकैः ।
कदम्बार्जुनसर्जै श्च पुष्पितै रुपशोभितम् ॥ १०
इयं च नळिनी रम्या फुल्लपङ्कजमण्डिता ।
नातिदूरे गुहायानौ भविष्यति नृपात्मज! ॥ ११
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।
पश्चाच्चैवोन्नता सौम्य! निवातेयं भविष्यति ॥ १२
गुहाद्वारे च सौमित्रे! शिला समतला शुभा ।
श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ १३
गिरिशृङ्ग मिदं तात! पश्य चोत्तरतश्शुभम् ।
भिन्नाञ्जनचयाकार मम्भोधरमिवोत्थितम् ॥ १४
दक्षिणस्या मपि दिशि स्थितं श्वेतमिवापरम् ।
कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ १५

प्राचीनवाहिनीं चैव नदीं भृश मकर्दमाम् ।
गुहायां पर्वतः पश्य लिकूटे जाह्नवीमिव ॥ १६
चम्पकै स्तिलकै स्तालैस्तमालै रतिमुक्तकैः ।
पद्मकै स्सरळै श्चैव अशोकै श्चैव शोभितम् ॥ १७
वानीरै स्तिरिशै श्चैव वकुळैः केतकै र्धवैः ।
हिन्तालै स्तिरिटै र्नीपै र्वेत्रकैः कृतमालकैः ॥ १८
तीरजै श्शोभिता भाति नानारूपै स्ततस्ततः ।
वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ १९
शतशः पक्षिसंघैश्च नानानादै र्विनादिता ।
एकैक मनुरक्तैश्च चक्रवाकै रलंकृता ॥ २०
पुळिनै रतिरम्यै श्च हंससारससेवितैः ।
प्रहसन्तीव भात्येषा नारी सर्वविभूषिता ॥ २१
क्वचि न्नीलोत्पलै श्छन्ना भाति रक्तोत्पलैः क्वचित् ।
क्वचि दाभाति शुक्लैश्च दिव्यैः कुमुदकुट्मलैः ॥ २२
पारिप्लवशतै र्जुष्टा बर्हिणक्रौञ्चनादिता ।
रमणीया नदी सौम्य! मुनिसंघै र्निषेविता ॥ २३
पश्य चन्दनवृक्षाणां पङ्क्ती स्सुरचिता इव ।
ककुभानां च दृश्यन्ते मनसे वोदिता स्समम् ॥ २४
अहो सुरमणीयोऽयं देश श्शत्रुनिषूदन! ।
दृढं रंस्याव सौमित्रे! साध्वत्र निवसावहै ॥ २५
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज! ॥ २६

गीतवादित्रनिर्घोष श्श्रूयते जयतां वर! ।
नर्दतां वानराणां च मृदङ्गा डम्बरै स्सह ॥ २७
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।
ध्रुवं नन्दति सुग्रीव स्संप्राप्य महतीं श्रियम् ॥ २८
"इत्युक्त्वा न्यवसत्तत्र राघव स्सह लक्ष्मणः ।
बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ ॥ २९
सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।
वसत स्तस्य रामस्य रतिरल्पाऽपि नाभवत् ॥ ३०
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ।
उदयाभ्युदितं दृष्ट्वा शशाङ्कंच विशेषतः ॥ ३१
आविवेश न तं निद्रा निशासु शयनं गतम् ।
तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ॥ ३२
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः ॥ ३३
"अलं वीर! व्यथां गत्वा न त्वं शोचितु मर्हसि ।
शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ॥ ३४
भवान्क्रियापरो लोके भवान् दैवपरायणः ।
आस्तिको धर्मशीलश्च व्यवसायीच राघव! ॥ ३५
न ह्यव्यवसित श्शत्रुं राक्षसं तं विशेषतः ।
समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम् ॥ ३६
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।
तत स्सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ ३७

पृथिवीमपि काकुत्स्थ! ससागरवनावलीम् ।
परिवर्तयितुं शक्तः किं मङ्क्षु पुनः रावणम् ॥ ३८
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयं मागतः ।
ततः ससराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ ३९
अहंतु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।
दीप्तै राहुतिभिः काले भस्मच्छन्न मिवानलम् ॥ ४०
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।
राघवः सुहृदं स्निग्ध मिदं वचन मब्रवीत् ॥ ४१
"वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण! त्वया ॥ ४२
एष शोकः परित्यक्त स्सर्वकार्यावसादकः ।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ ४३
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव ।
सुग्रीवस्य नदीनां च प्रसाद मनुपालयन् ॥ ४४
उपकारेण वीरस्तु प्रतीकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥" ४५
अथैव मुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलि स्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मन श्शुभम् ॥ ५६
"यथोक्त मेत त्तव सर्व मीप्सितं नरेन्द्र! कर्ता नचिरा द्वरीश्वरः ।
शरत्प्रतीक्षः क्षमता मिमं भवा न्जलप्रपातं रिपुनिग्रहे धृतः ॥ ४७
नियम्य कोपं प्रतिपाल्यतां शर त्क्षमस्व मासां श्चतुरो मया सह ।
वसाचलेऽस्मि न्मृगराजसेविते संवर्तयन् शत्रुवधे समुद्यमम् ॥ ४८

इति श्रीमत्किष्किन्धाकाण्डे सप्तविंशस्सर्गः ॥

॥ अष्टाविंशस्सर्गः ॥

स तदा वालिनं हत्वा सुग्रीव मभिषिच्यच ।
वस न्माल्यवतः पृष्ठे रामो लक्ष्मण मब्रवीत् ॥ १
"अयं सकाल स्संप्राप्त स्समयोऽद्य जलागमः ।
संपश्य त्वं नभो मेघै स्संवृतं गिरिसन्निभैः ॥ २
नवमासधृतं गर्भं भास्करस्य गभस्तिभिः ।
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ ३
शक्य मम्बर मारुह्य मेघसोपानपङ्क्तिभिः ।
कुटजार्जुनमालाभि रलंकर्तुं दिवाकरम् ॥ ४
सन्ध्यारागोत्थितै स्ताम्रै रन्तेष्वधिकपाण्डरैः ।
स्निग्धै रभ्रपटच्छेदै र्बद्धव्रगमिवाम्बरम् ॥ ५
मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् ।
आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ६
एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता ।
सीतेव शोकसंतप्ता मही वाष्पं विमुञ्चति ॥ ७
मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः ।
शक्य मञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ८
एषफुल्लार्जुन श्शैलः केतकै रधिवासितः ।
सुग्रीव इव शान्तारिर्धाराभि रभिषिच्यते ॥ ९
मेघकृष्णाजिनधराः धारा यज्ञोपवीतिनः ।
मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ १०

कशाभि रिव हैमीभि र्विद्युद्भिरिव ताडितम् ।
अन्तस्तनितनिर्घोषं सवेदन मिवाम्बरम् ॥ ११

नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मा ।
स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ १२

इमा स्ता मन्मथवतां हिताः प्रतिहता दिशः ।
अनुलिप्ता इव घनै र्नष्टग्रहनिशाकराः ॥ १३

क्वचिद्वाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् ।
कुटजान्पश्य सौमित्रे! पुष्पिता न्गिरिसानुषु ॥ १४

मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् ।
रजः प्रशान्तं सहिमोऽद्य वायु र्निदाघदोषप्रसराः प्रशान्ताः ।
स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नरास्स्वदेशान् ॥

संप्रस्थिता मानसवासलुब्धाः प्रियान्विता स्संप्रति चक्रवाकाः ।
अभीक्ष्ण वर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति ॥ १६

क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति ।
क्वचित्क्वचित्पर्वतसन्निरुद्धं रूपं यथा शान्तमहार्णवस्य ॥ १७

व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् ।
मयूरकेकाभि रनुप्रयातं शैलापगा श्शीघ्रतरं वहन्ति ॥ १८

रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम् ।
अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ १९

विद्युत्पताका स्सबलाकमाला श्शैलेन्द्रकूटाकृतिसन्निकाशाः ।
गर्जन्ति मेघा स्समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः ॥ २०

वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि ।
वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति ॥ २१
समुद्वहन्त स्सलिलातिभारं बलाकिनो वारिधरानदन्तः ।
महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति ॥ २२
मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपङ्क्तिः ।
वातावधूता वरपौण्डरीकी लम्बेव माला रचिताऽम्बरस्य ॥ २३
बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन ।
गात्रानुवृत्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन ॥ २४
निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागर मभ्युपैति ।
हृष्टाबलाका घन मभ्युपैति कान्ता सकामा प्रिय मभ्युपैति ॥ २५
जाता वनान्ता शिशिखिसंप्रवृत्ता जाताः कदम्बास्सकदम्बशाखाः ।
जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ २६
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति ।
नद्यो घना मत्तगजा वनान्ताः प्रियाविहीना शिखिनः प्लवङ्गाः ॥
प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु ।
प्रपातशब्दाकुलिता गजेन्द्रा स्सार्धं मयूरै स्समदा नदन्ति ॥ २८
धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः ।
क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २९
अङ्गारचूर्णोत्करसन्निकाशैः फलैस्सुपर्याप्तरसै स्समृद्धैः ।
जम्बूद्रुमाणां प्रविभान्ति शाखानिलीयमाना इव षट्पदौघैः ॥ ३०
तटित्पताकाभिरलंकृताना मुदीर्णगम्भीरमहार्णवाणाम् ।
विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥ ३१

मार्गानुगश्शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ।
युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्द्रः प्रतिसन्निवृत्तः ॥ ३२
क्वचित्प्रगीता इवपट्पदौघैः क्वचित्प्रनृत्ता इव नीलकण्ठैः ।
क्वचित्प्रमत्ता इव वारणेन्द्रै र्विभान्त्यनेकाश्रयिणो वनान्ताः ॥ ३३
कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमि र्नववारिपूर्णा ।
मयूरमत्ताभिरुतप्रनृत्तै रापानभूमिप्रतिमा विभाति ॥ ३४
मुक्तासकाशं सलिलं पतद्भै मुनिर्मलं पत्रपुटेषु लग्नम् ।
हृष्टा विवर्णच्छदना विहङ्गा स्सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ३५
षट्पादतन्त्री मधुराभिधानं प्लवङ्गमोदीरितकण्ठताळम् ।
आविष्कृतं मेघमृदङ्गनादै र्वनेषु संगीतमिव प्रवृत्तम् ॥ ३६
क्वचित्प्रवृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः ।
व्यालम्बबर्हाभरणै र्मयूरै र्वनेषु संगीतमिव प्रवृत्तम् ॥ ३७
स्वैनं र्वनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसन्निरुद्धाम् ।
अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहतानदन्ति ॥ ३८
नद्य स्समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा ।
हृतानवप्राभृतपूर्णभोगा द्रुतं स्वभर्तार मुपोपयान्ति ॥ ३९
नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नवारिपूर्णाः ।
दवाग्निदग्धेषु दवाग्निदग्धाश्शैलेषु शैला इव बद्धमूलाः ॥ ४०
प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि ।
चरन्ति नीपार्जुनवासितानि गजा स्सुरम्याणि वनान्तराणि ॥ ४१
नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि ।
कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति ॥ ४२

मत्ता गजेन्द्रामुदितागवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ।
रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरै स्सुरेन्द्रः ॥ ४३
मेघा स्समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः ।
नदीस्तटाकानि सरांसि वापी र्महीं च कृत्स्ना मपवाहयन्ति ॥ ४४
वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाता स्समुदीर्णघोषाः ।
प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलै र्विप्रतिपन्नमार्गाः ॥ ४५
नरैर्नरेन्द्रा इव पर्वतेन्द्रा स्सुरेन्द्रदत्तैः पवनोपनीतैः ।
घनाम्बुकुम्भै रभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥
घनोपगूढं गगनं सतारं नभास्करो दर्शन मभ्युपैति ।
नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४७
महान्ति कूटानि महीधराणां धाराभिघौतान्यधिकं विभान्ति ।
महाप्रमाणैर्विपुलैः प्रपातै र्मुक्ताकलापै रिव लम्बमानैः ॥ ४८
शैलोपलप्रस्खलमानवेगा श्शैलोत्तमानां विपुलाः प्रपाताः ।
गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त इवा वभान्ति ॥ ४९
शीघ्रप्रवेगा विपुलाः प्रपातानिर्धौतशृङ्गोपतला गिरीणाम् ।
मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते ॥ ५०
सुरतामर्दविच्छिन्ना स्स्वर्गस्त्रीहारमौक्तिकाः ।
पतन्तीवाकुला दिक्षु तोयधारा स्समन्ततः ॥ ५१
निलीयमानैर्विहगै र्निमीलद्भिश्च पङ्कजैः ।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ ५२
वृत्तायात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ।
वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ५३

मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ।
अय मध्यायसमय स्सामगाना मुपस्थितः ॥ ५४
निवृत्तकर्मायतनो नूनं संचितसंचयः ।
आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ५५
नून मापूर्यमाणाया स्सरय्वा वर्धते रयः ।
मां समीक्ष्य समायान्त मयोध्याया इव स्वनः ॥ ५६
इमा स्स्फीतगुणा वर्षा स्सुग्रीवस्सुख मश्नुते ।
विजितारि स्सदारश्च राज्ये महति च स्थितः ॥ ५७
अहन्तु हृतदारश्च राज्याच्च महतश्च्युतः ।
नदीकूल मिव क्षिन्न मवसीदामि लक्ष्मण ! ॥ ५८
शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः ।
रावणश्च महान् शत्रु रपारं प्रतिभाति मे ॥ ५९
अयात्रां चैव दृष्ट्वैमान्मासाश्च भृशदुर्गमान् ।
प्रणते चैव सुग्रीवे न मयाकिंचिदीरितम् ॥ ६०
अपि चातिपारक्लिष्टं चिरादारै स्समागतम् ।
आत्मकार्यगरीयस्त्वा द्वक्तुं नेच्छामि वानरम् ॥ ६१
स्वय मेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ६२
तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ! ।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ६३
उपकारेण वीरो हि प्रतिकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥" ६४

तमेव मुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शन मात्मन श्शुभम् ॥ ६५
"यथोक्त मेतत्तव सर्व मीप्सितं नरेन्द्र ! कर्ता नचिराद्वरीश्वरः ।
शरत्प्रतीक्षः क्षमता मिमं भवान्जलप्रपातं रिपुनिग्रहे धृतः ॥ ६६

इति श्रीमत्किष्किन्धाकाण्डे अष्टाविंशस्सर्गः ॥

॥ एकोनत्रिंशस्सर्गः ॥

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।
सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् ।
अत्यर्थ मसतां मार्ग मेकान्तगतमानसम् ॥ २
निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्त मभिप्रेतांस्सर्वानेव मनोरथान् ॥ ३
स्वां च पत्नी मभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्त महो राज्ञं कृतार्थं विगतज्वरम् ॥ ४
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणा मनवेक्षकम् ॥ ५
उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ७

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ॥ ८
हरीश्वर मुपागम्य हनूमान्वाक्यमब्रवीत् ।
" राज्यं प्राप्तं यशश्चैव कौली श्री रभिवर्धिता ॥ ९
मित्राणां संग्रह श्शेषस्तं भवान्कर्तु मर्हति ।
यो हि मित्रेषु कालज्ञस्सततं साधु वर्तते ॥ १०
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ।
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ! ॥ ११
समवेतानि सर्वाणि स राज्यं महदश्नुते ।
तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये ॥ १२
मित्रार्थं मभिनीतार्थं यथावत्कर्तु मर्हति ।
संत्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते ॥ १३
संभ्रमाद्धि कृतोत्साह स्सोऽनर्थैर्नावरुध्यते ।
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ॥ १४
सकृत्वा महतोऽप्यर्था न्मित्रार्थेन युज्यते ।
यदिदं वीरकार्यं नो मित्रकार्यं मरिन्दम ! ॥ १५
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।
तदिदं वीर ! कार्यं ते कालातीत मरिन्दम ! ॥ १६
नच कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणोऽपि सन्प्राज्ञ स्तव राज ! न्वशानुगः ॥ १७
कुलस्य हेतुः स्फीतस्य दीर्घबन्धु श्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ १८

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर! हरिश्रेष्ठानाज्ञापयितु महेसि ॥ १९
न हि तावद्भवेत्कालो व्यतीत श्चोदनादृते ।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ २०
अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर! ।
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ २१
शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर! ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किन्न सज्जसे ॥ २२
कामं खलु शरै श्शक्त स्सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ २३
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्या मपि चाम्बरे ॥ २४
न देवा नच गन्धर्वा नासुरा न मरुद्गणाः ।
नच यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ २५
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।
रामस्यार्हसि पिङ्गेश! कर्तुं सर्वात्मना प्रियम् ॥ २६
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।
कस्यचित्सज्जतेऽस्माकं कपीश्वर! तवाज्ञया ॥ २७
तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु ।
हरयोऽप्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ॥ २८
तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् ।
सुग्रीव स्सत्त्वसंपन्न श्चकार मति मुत्तमाम् ॥ २९

ससंदिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्याना मुपसंग्रहे ॥ ३०
यथा सेना समग्रा मे यूथपाश्च सर्वशः ।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥ ३१
ये त्वन्तपालाः प्लवगा इशीघ्रगा व्यवसायिनः ।
समानयन्तु ते सैन्यं त्वरिता इशासनान्मम ॥ ३२
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ।
त्रिपञ्चरात्रा दूर्ध्वं यः प्राप्नुया न्नेह वानरः ॥ ३३
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ।
हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥

इति श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशस्सर्गः ॥

॥ त्रिंशस्सर्गः ॥

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २
कामवृत्तंच सुग्रीवं नष्टां च जनकात्मजाम् ।
बुद्ध्वा काल मतीतं च मुमोह परमातुरः ॥ ३
सतु संज्ञा मुपागम्य मुहूर्तान्मतिमान्पुनः ।
मनस्था मपि वैदेहीं चिन्तयामास राघवः ॥ ४

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥ ५
दृष्ट्वाच विमलं व्योम गतविद्युद्बलाहकम् ।
सारसारवसंघुष्टं विललापार्तया गिरा ॥ ६
सारसारवसन्नादै स्सारसारवनादिनी ।
याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥ ७
पुष्पितां श्चासनान्दृष्ट्वा काञ्चना निव निर्मलान् ।
कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ ८
या पुरा कलहंसानां स्वरेण कलभाषिणी ।
बुध्यते चारुसर्वाङ्गी साऽद्यमे बुध्यते कथम् ॥ ९
निस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ १०
सरांसि सरितो वापीः काननानि वनानिच ।
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥ ११
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।
न दूरं पंडयेत्कामश्शरद्रुणनिरन्तरः ॥" १२
एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।
विहङ्ग इव सारङ्ग स्सलिलं त्रिदशेश्वरात् ॥ १३
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणोऽग्रजम् ॥ १४
तं चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी ।
भ्रातर्विषादात्परितापदीन स्समीक्ष्य सौमित्रि रुवाच रामम् ॥ १५

"किमार्य! कामस्य वशं गतेन किमात्मपौरुष्यपराभवेन ।
अयं सदा संहियते समाधिः किमत्र योगेन निवर्तितेन ॥ १६
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतंच कालम् ।
सहायसामर्थ्य मदीनसत्त्व! स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७
नजानकी मानववंशनाथ! त्वया सनाथा सुलभा परेण ।
नचाग्निधूडां ज्वलिता मुपेत्य नदह्यते वीरवराऽर्ह! कश्चित् ॥" १८
सलक्षणं लक्ष्मण मप्रधृष्यं स्वभावजं वाक्य मुवाच रामः ।
हितंच पथ्यंच नयप्रसक्तं ससामधर्मार्थसमाहितं च ॥ १९
"निस्संशयं कार्यमवेक्षणीयं क्रियाविशेषो ह्यनुवर्तितव्यः ।
ननु प्रवृत्तस्य दुरासदस्य कुमार! कार्यस्य फलं नचिन्त्यम् ॥" २०
अथ पद्मपलाशाक्षीं मैथिली मनुचिन्तयन् ।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१
"तर्पयित्वा सहस्राक्ष स्सलिलेन वसुन्धराम् ।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२
स्निग्धगम्भीरनिर्घोषा इशैलद्रुमपुरोगमाः ।
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज! ॥ २३
नीलोत्पलदलश्यामा श्श्यामी कृत्वा दिशो दश ।
विमदा इव मातङ्गा श्शान्तवेगाः पयोधराः ॥ २४
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।
चरित्वा विरता स्सौम्य! वृष्टिवाता स्समुद्यताः ॥ २५
घनानां वारणानां च मयूराणांच लक्ष्मण! ।
नादः प्रस्रवणानांच प्रशान्तस्सहसाऽनघ! ॥ २६

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।
अनुलिप्ता इवाऽभान्ति गिरय श्चित्रदीप्तिभिः ॥ २७
दर्शयन्ति शरन्नद्यः पुळिनानि शनैश्शनैः ।
नवसङ्गमसव्रीडा जघनानीव योषितः ॥ २८
शाखासु सप्तच्छ दपादपानां प्रभासुतारार्कनिशाकराणाम् ।
लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता २९
संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मी श्शरत्काललगुणोपनीता ।
सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ ३०
सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दै रनुगीयमानः ।
मत्तद्विपानां पवनोऽनुसारी दर्पं वनेष्वभ्यधिकं करोति ॥ ३१
अभ्यागतै श्चारुविशालपक्षै स्सरःप्रियैः पद्मरजोवकीर्णैः ।
महानदीनां पुळिनोपयातैः क्रीडन्ति हंसास्सहचक्रवाकैः ॥ ३२
मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु ।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता ॥ ३३
नभस्समीक्ष्याम्बुधरै र्विमुक्तं विमुक्तबर्हाभरणा वनेषु ।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ ३४
मनोज्ञगन्धैः प्रियकै रनल्पैः पुष्पातिभारावनताग्रशाखैः ।
सुवर्णगौरै र्नयनाभिरामै रुद्योतितानीव वनान्तराणि ॥ ३५
प्रियान्वितानां नलिनीप्रियाणां वनेरतानां कुसुमोद्धतानाम् ।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः ॥ ३६
व्यभ्रं नभश्शस्यविधौतवर्णं कृशप्रवाहानि नदीजलानि ।
कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥

सूर्यातपक्रामणनष्टपङ्का भूमि स्समुत्पादितसान्द्ररेणुः ।
अन्योन्यवैरोत्सुकयुतानां युद्धागकालोऽद्य नराधिपानाम् ॥ ३८
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्क्षिताङ्गाः ।
मदोत्कटा स्संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ ३९
स मन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः ।
मदान्वितं संपरिवार्य यान्तं वनेषु भर्तार मनुप्रयान्ति ॥ ४०
त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् ।
निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः ॥ ४१
वित्रास्य कारण्डवचक्रवाकान्महारवै र्भिन्नकटा गजेन्द्राः ।
सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥ ४२
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ।
ससारसारावविनादितासु नदीषु हृष्टानि पतन्ति हंसाः ॥ ४३
नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् ।
प्लवङ्गमानां च गतोत्सवानां द्रुतं रवा स्संप्रति संप्रणष्टाः ॥ ४४
अनेकवर्णा स्सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः ।
क्षुधार्दिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः ॥ ४५
चञ्चच्चन्द्रकरस्पर्श हर्षोन्मीलिततारका ।
अहो रागवती संध्या जहाति स्वय मम्बरम् ॥ ४६
रात्रि श्शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा ।
ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥ ४७
विपक्वशालि प्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः ।
नभ स्समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ॥ ४८

सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति ।
घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥ ४९
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमाना मधिकाऽद्य लक्ष्मीर्वराङ्गनाना मिव भूषितानाम् ॥
वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः ।
सम्मूर्छितो गह्वरगोवृषाणा मन्योन्य मापूरयतीव शब्दः ॥ ५१ ह्व
नवैर्नदीनां कुसुमप्रहासैर्व्याधूयमानैर्मृदुमारुतेन ।
धौतामलक्षौमपटप्रकाशैः कुलानि काशैरुपशोभितानि ॥ ५२
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताष्षट्चरणाः प्रहृष्टाः ।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ॥ ५३
जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वन श्शालिवनं विपक्वम् ।
मृदुश्च वायुर्विमलश्च चन्द्र श्शंसन्ति वर्षव्यपनीतकालम् ॥ ५४
मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः ।
कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विवकामिनीनाम् ॥ ५५
सचक्रवाकानि सशैवलानि काशैर्दुकूलै रिव संवृतानि ।
सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥ ५६
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु ।
गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः ॥ ५७
लोकं सुवृष्ट्या परितोषयित्वा नदी स्तटाकानि च पूरयित्वा ।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः ॥
प्रसन्नसलिला स्सौम्य! कुररीभि र्विनादिताः ।
चक्रवाक गणाकीर्णा विभान्ति सलिलाशयाः ॥ ५९

असनास्सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥ ६०
हंससारसचक्राह्वैः कुररैश्च समन्ततः ।
पुञ्जितान्यवकीर्णानि नदीनां पश्य लक्ष्मण ! ॥ ६१
अन्योन्यवद्धवैराणां जिगीषूणां नृपात्मज ! ।
उद्योगसमय स्सौम्य ! पार्थिवानां मुपस्थितः ॥ ६२
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ! ।
नचपश्यामि सुग्रीव मुद्योगं वा तथाविधम् ॥ ६३
चत्वारो वार्षिकामासा गता वर्षशतोपमाः ।
मम शोकाभिभूतस्य सौम्य सीता मपश्यतः ॥ ६४
चक्रवाकीव भर्तारं प्रष्ठतोऽनुगता वनम् ।
विषमं दण्डकारण्य मुद्यानमिव यांऽऽगता ॥ ६५
प्रियाविहीने दुःखार्ते ह्रतराज्ये विवासिते ।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ! ॥ ६६
'अनाथो ह्रतराज्योऽयं रावणेन च धर्षितः ।
दीनो दूरगृहः कामी मां चैव शरणं गतः ॥' ६७
इत्येतैः कारणै स्सौम्य ! सुग्रीवस्य दुरात्मनः ।
अहं वानरराजस्य परिभूतः परन्तप ! ॥ ६८
सकालं परिसंख्याय सीतायाः परिमार्गणे ।
कृतार्थ स्समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ ६९
त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् ।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ७०

अर्थिना मुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
आशां संश्रित्य यो हन्ति सलोके पुरुषाधमः ॥ ७१
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
सत्येन प्रतिगृह्णाति स वीरः पुरुषोत्तमः ॥ ७२
कृतार्थाह्यकृतार्थानां मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ७३
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ ७४
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।
निर्घोष मिव वज्रस्य पुनस्संश्रोतु मिच्छति ॥ ७५
काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे ।
त्वत्सहायस्य मे वीर! न चिन्तास्या नृपात्मज! ॥ ७६
यदर्थमयमारम्भः कृतः परपुरञ्जय! ।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ ७७
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतां श्चतुरो मासान्विहरन्नाव बुध्यते ॥ ७८
सामात्यपरिषत्क्रीडन्पानमेवोपसेवते ।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ ७९
उच्यतां गच्छ सुग्रीव त्वया वत्स! महाबल! ।
मम रोषस्य यद्रूपं ब्रूयाश्चैन मिदं वचः ॥ ८०
"नच संकुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव! मा वालिपथ मन्वगाः ॥ ८१

एक एव रणे वाली शरेण निहतो मया ।
त्वां तु सत्या दतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ८२
तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ! ।
तत्तद्ब्रूहि नरश्रेष्ठ ! त्वर कालव्यतिक्रमः ॥ ८३
कुरुष्व सत्यं मयि वानरेश्वर ! प्रतिश्रुतं धर्म मवेक्ष्य शाश्वतम् ।
मा वालिनं प्रेत्यगतो यमक्षयं त्वमद्य पश्ये र्ममचोदितै इशरैः ॥ ८४
सपूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।
चकार तीव्रां मति मुग्रतेजा हरीश्वरे मानववंशनाथः ॥ ८५

इति श्रीमत्किष्किन्धाकाण्डे त्रिंशस्सर्गः ॥

॥ एकत्रिंशस्सर्गः ॥

सकामिनं दीन मदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् ।
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वज मित्युवाच ॥ १
"न वानरः स्थास्यति साधुवृत्ते न मंस्यते कर्मफलानुषङ्गान् ।
न भोक्ष्यते वानरराज्यलक्ष्मीं तथा हि नाभिक्रमतेऽस्य बुद्धिः ॥ २
मतिक्षयाद्भ्रात्र्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः ।
हतोऽग्रजं पश्यतु वीर ! तस्य नराज्यमेवं विगुणस्य देयम् ॥ ३
नधारये कोप मुदीर्णवेगं निहन्मि सुग्रीव मसत्य मद्य ।
हरिप्रवीरै स्सह वालिपुत्रो नरेन्द्र ! पत्न्या विचयं करोतु ॥" ४
तमात्तबाणासन मुत्पतन्तं निवेदितार्थं रणचण्डकोपम् ।
उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयंच वाक्यम् ॥ ५

"नहि वै त्वद्विधो लोके पापमेवं समाचरेत् ।
कोपमार्येण यो हन्ति सवीरः पुरुषोत्तमः ॥ ६
नेदं मय्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ! ।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ ७
सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्ययं ॥" ८
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ९
तत इङ्गुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ १०
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ।
प्रगृह्य गिरिशृङ्गाभं मन्दर स्सानुमानिव ॥ ११
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।
बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तथा ॥ १२
कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३
सालतालाश्वकर्णांश्च तरसा पातयन्बहून् ।
पर्यस्य गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ १४
शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ।
दूरमेकपदं त्यक्त्वा ययौ कार्यवशादृतम् ॥ १५
तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् ।
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे ॥ १६

रोषात्प्रस्फुरमाणोष्ठ स्सुग्रीवं प्रति लक्ष्मणः ।
ददर्श वानरान्भीमा न्किष्किन्धाया बहिश्चरान् ॥ १७
तं दृष्ट्वा वानरास्सर्वे लक्ष्मणं पुरुषर्षभम् ।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ॥ १८
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ।
तान्गृहीत प्रहरणान्हरी न्दृष्ट्वातु लक्ष्मणः ॥ १९
बभूव द्विगुणं क्रुद्धो बह्निन्धन इवानलः ।
तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः ॥ २०
कालमृत्यु युगान्ताभं शतशो विद्रुतादिशः ।
ततस्सुग्रीव भवनं प्रविश्य हरिपुङ्गवाः ॥ २१
क्रोध मागमनं चैव लक्ष्मणस्य न्यवेदयन् ।
तारया सहितः कामी सक्तः कपिवृषो रहः ॥ २२
न तेषां कपिवीराणां शुश्राव वचनं तदा ।
ततस्सचिवसंदिष्टा हरयो रोमहर्षणाः ॥ २३
गिरिकुञ्जर मेघाभा नगर्या निर्ययु स्तदा ।
नखदंष्ट्रायुधा घोरा स्सर्वे विकृतदर्शनाः ॥ २४
सर्वे शार्दूलदर्पाश्च सर्वेच विकृताननाः ।
दशनागबलाः केचित्केचि दशगुणोत्तराः ॥ २५
केचि न्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।
(सन्ति चौघबलाः केचि त्केचि द्वायुबलोत्तराः ॥ २६
अप्रमेयबलाः केचित्तत्राऽसन्हरिपुंगवाः ।
तेन वानरसैन्येन सुग्रीवस्य महात्मनः ॥ २७

पर्यधावत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।]
कृत्स्नां हि कपिभि र्व्याप्तां द्रुमहस्तै र्महाबलैः ॥ २८
अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ।
ततस्ते हरयस्सर्वे प्राकारपरिघान्तरात् । २९
निष्क्रम्योदग्रसत्त्वास्तु तस्थु राविष्कृतं तदा ।
सुग्रीवस्य प्रमादंच पूर्वजं चार्तमात्मवान् ॥ ३०
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ।
सदीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ॥ ३१
बभूव नरशार्दूल स्सधूम इव पावकः ।
बाणशल्यस्फुरज्जिह्व स्सायकासनभोगवान् ॥ ३२
स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः ।
तं दीप्त मिव कालाग्निं नागेन्द्र मिव कोपितम् ॥ ३३
समासाद्याङ्गद स्त्रासा द्विषाद मगम द्भृशम् ।
सोऽङ्गदं रोषताम्राक्ष स्संदिदेश महायशाः ॥ ३४
"सुग्रीवः कथ्यतां वत्स ! ममागमनमित्युत ।
एष रामानुजः प्राप्तस्त्वत्सकाश मरिन्दमः ॥ ३५
भ्रातृव्यसन संतप्तो द्वारि तिष्ठति लक्ष्मणः ।
तस्य वाक्ये यदि रुचिः क्रियतां साधुवानर ! ॥ ३६
इत्युक्त्वा शीघ्र मागच्छ वत्स ! वाक्य मरिन्दम ! ।"
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ॥ ३७
पितु स्समीप मागम्य 'सौमित्रिरय मागतः ।'
अथाङ्गदस्तस्य वचो निशम्य संभ्रान्तभावः परिदीनवक्त्रः ॥ ३८

निपत्य तूर्णं नृपतेस्तरस्वी ततः कुमारश्चरणौ ववन्दे ।
संगृह्य पादौ पितुरप्रतेजा जग्राह मातुः पुनरेव पादौ ॥ ३९
पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ।
स निद्रामदसंवीतो वानरो न विबुद्धवान्॥ ४०
बभूव मदमत्तश्च मदनेन च मोहितः ।
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ॥ ४१
प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ।
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ॥ ४२
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ।
तेन शब्देन महता प्रत्यबुध्यत वानरः ॥ ४३
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ।
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ॥ ४४
मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ ।
प्लक्षश्चैव प्रभावश्च मन्त्रिणा वर्थधर्मयोः ॥ ४५
वक्तुमुचावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ।
प्रसादयित्वा सुग्रीवं वचनै स्सामनिश्चितैः ॥ ४६
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ।
[सुग्रीवसचिवा स्सर्वे मन्त्रार्थे समुपाविशन् ॥ ४७
विनीतश्च सुषेणश्च नीलोऽथ नळ एवच ।
अङ्गदो वालिसूनुश्च हनूमां श्चैव बुद्धिमान् ॥ ४८
एते सर्वे महात्मान स्सुग्रीवं वानरोत्तमाः ।
आसीनं पर्युपासन्त शक्रं सुरगणा इव ॥ ४९

बलविक्रमसंयुक्ता मन्त्रे च परिनिष्ठिताः ।
सुग्रीवसचिवा स्सर्वे मन्त्राणा मर्थसिद्धये ॥ ५०

वक्तु मुच्चावचं प्राप्तं लक्ष्मणं ते शशंसिरे ।
प्रसादयित्वा सुग्रीवं वचनै स्सामनिश्चितैः ॥ ५१

उवाच हनुमान्वीरो यथा शक्रं बृहस्पतिः ।
" सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ॥ ५२

वयस्यभावं संप्राप्तौ राज्याहौं राज्यदायिनौ ;
तयो रेको धनुष्पाणि र्द्वारि तिष्ठति लक्ष्मणः ॥ ५३

यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः ।
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ॥ ५४

व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ।
अयं च दयितो राजं ! स्तारायां स्तनयोऽङ्गदः ॥ ५५

लक्ष्मणेन सकाशं ते प्रेषित स्त्वरयाऽनघ ! ।
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् ॥ ५६

वानरान्वानरपते ! चक्षुषा प्रदहन्निव ।
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्सह बन्धुभिः ॥ ५७

गच्छ शीघ्रं महाराज ! रोषो ह्यस्य निवर्त्यताम् ।
यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ॥ ५८

राजं ! स्तिष्ठस्व समये भव सत्यप्रतिश्रवः ।"

इति श्रीमत्किष्किन्धाकाण्डे एकत्रिंशस्सर्गः ॥

॥ द्वात्रिंशस्सर्गः ॥

अङ्गदस्य वचः श्रुत्वा सुग्रीव स्सचिवैः स्सह ।
लक्ष्मणं कुपितं श्रुत्वा सुमोचासन मात्मवान् ॥ १

सचिवानब्रवी द्वाक्यं निश्चित्य गुरुलाघवम् ।
मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥ २

"न मे दुर्व्याहृतं किंचि न्नापि मे दुरनुष्ठितम् ।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ ३

असुहृद्भिर्ममाभित्रैर्नित्य मन्तरदर्शिभिः ।
मम दोषानसंभूतान् श्रावितो राघवानुजः ॥ ४

अत्र तावद्यथाबुद्धि सर्वं रेव यथाविधि ।
भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः ॥ ५

न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ।
मित्रं त्वस्थानकुपितं जनयत्येव संभ्रमम् ॥ ६

सर्वथा सुकरं मित्रं दुष्करं परिपालनम् ।
अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥ ७

अतोऽनिमित्तं त्रस्तोऽहं रामेण तु महात्मना ।
यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥" ८

सुग्रीवेणैव मुक्तस्तु हनूमान्हरिपुङ्गवः ।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ ९

"सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर ! ।
न विस्मरसि सुस्निग्ध मुपकारकृतं शुभम् ॥ १०

राघवेण तु वीरेण भय मुत्सृज्य दूरतः ।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ ११
सर्वथा प्रणया त्कुद्धो राघवो नात्र संशयः ।
भ्रातरं संप्रहितवान्लक्ष्मणं लक्ष्मिवर्धनम् ॥ १२
त्वं प्रमत्तो न जानीषे कालं कालविदां वर! ।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ १३
निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका ।
प्रसन्नाश्च दिश स्सर्वा स्सरितश्च सरांसि च ॥ १४
प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव! ।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽय मिहागतः ॥ १५
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ।
वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ १६
कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥ १७
नियुक्तैर्मन्त्रिभि र्वाच्योह्यवश्यं पार्थिवो हितम् ।
अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ १८
अभिक्रुद्ध स्समर्थो हि चापमुद्यम्य राघवः ।
सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥ १९
नस क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ २०
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्ससुहृज्जनः ।
राजन्! स्तिष्ठस्व समये भर्तुर्भार्येव तद्वशः ॥ २१

न रामरामानुजशासनं त्वया कपीन्द्र! युक्तं मनसाऽप्यपोहितुम्।
मनोहि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ २२

इति श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशस्सर्गः ॥

॥ त्रयस्त्रिंशस्सर्गः ॥

अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा।
प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् ॥ १

द्वारस्था हरयस्तत्र महाकाया महाबलाः।
बभूवु र्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २

निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्।
बभूवु र्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ ३

सतां रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम्।
रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ॥ ४

हर्म्यप्रासाद संबाधां नानापण्योपशोभिताम्।
सर्वकामफलैर्वृक्षैः पुष्पितै रुपशोभिताम् ॥ ५

देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः।
दिव्यमाल्याम्बरधरै श्शोभितां प्रियदर्शनैः ॥ ६

चन्दनागरुपद्मानां गन्धै स्सुरभिगन्धिनाम्।
मैरेयाणां मधूनां च सम्मोदित महापथाम् ॥ ७

विन्ध्यमेरु गिरिप्रख्यैः प्रासादैः परिभूषिताम्।
ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ ८

अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्यच ।
गवयस्य गवाक्षस्य गजस्य शरभस्यच ॥ ९
विद्युन्माले श्च संपाते स्सूर्याक्षस्य हनूमतः ।
वीरबाहो स्सुबाहोश्च नळस्यच महात्मनः ॥ १०
कुमुदस्य सुषेणस्य तारजाम्बवतो स्तथा ।
दधिवक्त्रस्य नीलस्य सुपाटल सुनेत्रयोः ॥ ११
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ १२
पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानिच ।
प्रभूत धनधान्यानि स्त्रीरत्नै श्शोभितानिच ॥ १३
पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् ।
वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ १४
शुभ्रैः प्रासादशिखरैः कैलासशिखरोपमैः ।
सर्वकामफलै र्वृक्षैः पुष्पितै रुपशोभितम् ॥ १५
महेन्द्रदत्तै श्श्रीमद्भि र्नीलजीमूत सन्निभैः ।
दिव्यपुष्पफलै र्वृक्षै श्शीतच्छायै र्मनोरमैः ॥ १६
हरिभि स्संवृतद्वारं बलिभि श्शस्त्रपाणिभिः ।
दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ १७
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ।
अवार्यमाण स्सौमित्रि र्महाभ्र मिव भास्करः ॥ १८
स सप्तकक्ष्या धर्मात्मा नानाजनसमाकुलाः ।
प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत् ॥ १९

हैमराजतपर्यङ्कै र्बहुभि श्च वरासनैः ।
महार्हास्तरणोपेतै स्तत्र तत्रोपशोभितम् ॥ २०
प्रविश न्नेव सततं शुश्राव मधुरस्वरम् ।
तन्त्रीगीत समाकीर्णं समगीतपदाक्षरम् ॥ २१
बह्वीश्च विविधाकारा रूपयौवनगर्विताः ।
स्त्रिय स्सुग्रीवभवने ददर्श सुमहाबलः ॥ २२
दृष्ट्वाऽभिजनसंपन्ना श्चित्रमाल्यकृतस्रजः ।
फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ २३
नातृप्ता न्नापि चाव्यग्रा न्नानुदात्तपरिच्छदान् ।
सुग्रीवानुचरां श्चापि लक्षयामास लक्ष्मणः ॥ २४
कूजितं नूपुराणां च काञ्चीनां निनदं तथा ।
सश्रिशम्य तत इश्रीमां स्सौमित्रि र्लज्जितोभवत् ॥ २५
रोषवेग प्रकुपित श्श्रुत्वा चाभरणस्वनम् ।
चकार ज्यास्वनं वीरो दिशश्शब्देन पूरयन् ॥ २६
चारित्रेण महाबाहु रपकृष्ट स्सलक्ष्मणः ।
तस्या वेकान्तमाश्रित्य रामकोपसमन्वितः ॥ २७
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः ।
विज्ञायाऽगमनं त्रस्तस्संचचाल वरासनात् ॥ २८
"अङ्गदेन यथामह्यं पुरस्ता त्प्रतिवेदितम् ।
सुव्यक्त मेषसंप्राप्तः सौमित्रि र्भ्रातृवत्सलः ॥" २९
अङ्गदेन समाख्यातं ज्यास्वनेनच वानरः ।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ ३०

ततस्तारां हरिश्रेष्ठ स्सुग्रीवः प्रियदर्शनाम् ।
उवाच हित मव्यग्र स्त्राससंभ्रान्तमानसः ॥ ३१
" किन्नु तत्कारणं सुभ्रु ! प्रकृत्या मृदुमानसः ।
सरोष इव संप्राप्तो येनायं राघवानुजः ॥ ३२
किं पश्यसि कुमारस्य रोषस्थान मनिन्दिते ! ।
नखल्वकारणे कोप माहरेन्नरसत्तमः ॥ ३३
यदस्य कृतमस्माभि र्बुध्यसे किंचिदप्रियम् ।
तद्बुद्ध्या संप्रधार्याशु क्षिप्रमर्हसि भाषितुम् ॥ ३४
अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि ! ।
वचनै स्सान्त्वयुक्तैश्च प्रसादयितु मर्हसि ॥ ३५
त्वद्दर्शनविशुद्धात्मा न सकोपं करिष्यति ।
नहि स्त्रीषु महात्मानः कचित्कुर्वन्ति दारुणम् ॥ ३६
त्वयासान्त्वै रुपक्रान्तं प्रसन्नेन्द्रियमानसम् ।
ततः कमलपत्राक्षं द्रक्ष्यास्यह मरिन्दमम् ॥" ३७
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा ।
सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयष्टिः ॥ ३८
सतां समीक्ष्यैव हरीशपत्नीं तस्था वुदासीनतया महात्मा ।
अवाङ्मुखोऽभू न्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ ३९
सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः ।
उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम् ॥ ४०
" किं कोपमूलं मनुजेन्द्रपुत्र ! कस्ते न संतिष्ठति वाङ्निदेशे ।
कश्शुष्कवृक्षं वन मापतन्तं दवाग्नि मासीदति निर्विशङ्कः ॥" ४१

स तस्या वचनं श्रुत्वा सान्त्वपूर्वं मशङ्कितम् ।
भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्य मब्रवीत् ॥ ४२
"किं मयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः ।
भर्ता भर्तृहिते युक्ते न चैन मवबुध्यसे ॥ ४३
न चिन्तयति राज्यार्थं नास्मान् शोकपरायणान् ।
सामात्यपरिषत्तारे ! पानमेवोपसेवते ॥ ४४
समासां श्रुतुरः कृत्वा प्रमाणं प्लवगेश्वरः ।
व्यतीतां स्तान्मदव्यग्रो विहरन्नावबुध्यते ॥ ४५
नहि धर्मार्थसिद्ध्यर्थं पान मेवं प्रशस्यते ।
पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥ ४६
धर्मलोपो महां स्तावत्कृते ह्यप्रतिकुर्वतः ।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ ४७
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् ।
तदृयंतु परित्यक्तं नतु धर्मे व्यवस्थितम् ॥ ४८
तदेवं प्रस्तुते कार्ये कार्य मस्माभि रुत्तरम् ।
यत्कार्यं कार्यतत्त्वज्ञे ! तदुदाहर्तु मर्हसि ॥" ४९
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् ।
तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥ ५०
"न कोपकालः क्षितिपालपुत्र ! नचातिकोप स्स्वजने विधेयः ।
त्वदर्थकामस्य जनस्य तस्य प्रमाद मर्ह्यसि वीर ! सोढुम् ॥ ५१
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्या दपकृष्टसत्त्वे ।
कस्त्वद्विधः कोपवशं हि गच्छे त्सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ ५२

जानामि रोषं हरिवीरबन्धो र्जानामि कार्यस्य च कालसङ्गम् ।
जानामि कार्यं त्वयि यत्कृतं नस्तच्चापि जानामि यदत्र कार्यम् ॥
तच्चापि जानामि यथा विषह्यं बलं नरश्रेष्ठ! शरीरजस्य ।
जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीव मसक्तमद्य ॥ ५४
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः ।
न देशकालौ हि नचार्थधर्मा वपेक्षते काम रतिर्मनुष्यः ॥ ५५
तं कामवृत्तं मम सान्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम् ।
क्षमस्व तावत्परवीरहन्त! स्वद्भ्रातरं वानरवंशनाथम् ॥ ५६
महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः ।
अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥" ५७
इत्येव मुक्त्वा वचनं महार्थं सा वानरी लक्ष्मण मप्रमेयम् ।
पुन स्सखेलं मदविह्वलं च भर्तु र्हितं वाक्य मिदं बभाषे ॥ ५८
"उद्योगस्तु चिराज्ञप्त स्सुग्रीवेण नरोत्तम! ।
कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ ५९
आगता हि महावीर्या हरयः कामरूपिणः ।
कोटीशतसहस्राणि नानानगनिवासिनः ॥ ६०
तदागच्छ महाबाहो! चारित्रं रक्षितं त्वया ।
अच्छलं मित्रभावेन सतां दारावलोकनम् ॥" ६१
तारयाचाभ्यनुज्ञात स्त्वरया चापि चोदितः ।
प्रविवेश महाबाहु रभ्यन्तर मरिन्दमः ॥ ६२
तत स्सुग्रीव मासीनं काञ्चने परमासने ।
महार्हास्तरणोपेते ददर्शादित्यसन्निभम् ॥ ६३

दिव्याभरण चित्राङ्गं दिव्यरूपं यशस्विनम् ।
दिव्यमाल्याम्बरधरं महेन्द्र मिव दुर्जयम् ॥ ६४
दिव्याभरणमाल्याभिः प्रमदाभि स्समावृतम् ।
[लक्ष्मणः परवीरघ्नो रामकोपाभिपीडितः ॥] ६५
संरब्धतररक्ताक्षो बभूवान्तकसन्निभः ।
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ।
ददर्श सौमित्रि मदीनसत्त्वं विशालनेत्र स्सुविशालनेत्रम् ॥ ६६

इति श्रीमत्किष्किन्धाकाण्डे त्रयस्त्रिंशस्सर्गः ॥

॥ चतुस्त्रिंशस्सर्गः ॥

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ १
क्रुद्धं निःश्वसमानं तं प्रदीप्त मिव तेजसा ।
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ २
उत्पपात हरिश्रेष्ठो हित्वासौवर्ण मासनम् ।
महान्महेन्द्रस्य यथा स्खलंकृत इव ध्वजः ॥ ३
उत्पतन्त मनूत्पेतू रुमाप्रभृतयः स्त्रियः ।
सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ ४
संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः ।
बभूवावस्थित स्तत्र कल्पवृक्षो महानिव ॥ ५
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।
अब्रवील्लक्ष्मणः क्रुद्धस्सतारं शशिनं यथा ॥ ६

"सत्त्वाभिजनसंपन्नस्सानुक्रोशो जितेन्द्रियः ।
कृतज्ञ स्सत्यवादी च राजा लोके महीयते ॥ ७
यस्तु राजा स्थितो धर्मे मित्राणा मुपकारिणाम् ।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ ८
शत मश्वानृते हन्ति सहस्रं तु गवानृते ।
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।
कृतघ्न स्सर्वभूतानां स वध्यः प्लवगेश्वर ! ॥ १०
गीतोऽयं ब्रह्मणा श्लोक स्सर्वलोकनमस्कृतः ।
दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवङ्गम ! ॥ ११
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२
अनार्य स्त्वं कृतघ्नश्च मिथ्यावादी च वानर ! ।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३
ननु नाम कृतार्थेन त्वया रामस्य वानर ।
सीताया मार्गणे यत्नः कर्तव्यः कृत मिच्छता ॥ १४
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।
न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥ १५
महाभागेन रामेण पापः करुणवेदिना ।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ १६
कृतं चे नाभिजानीषे रामस्याक्लिष्टकर्मणः ।
सद्य स्त्वं निशितैर्बाणै र्हतो द्रक्ष्यसि वालिनम् ॥ १७

न च संकुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव! मा वालिपथ मन्वगाः ॥ १८
न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान् शरान्पश्यसि वज्रसन्निभान् ।
तत स्सुखं नाम निषेवसे सुखी न रामकार्यं मनसाऽप्यवेक्षसे ॥"

इति श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशस्सर्गः ॥

॥ पञ्चत्रिंशस्सर्गः ॥

तथा ब्रुवाणं सौमित्रिं प्रदीप्त मिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ १
"नैवं लक्ष्मण! वक्तव्यो नायं परुष मर्हति ।
हरीणा मीश्वर श्श्रोतुं तव वक्राद्विशेषतः ॥ २
नै वाकृतज्ञ स्सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर! न जिह्मश्च कपीश्वरः ॥ ३
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर! सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४
रामप्रसादात्कीर्तिं च कपि राज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप! ॥ ५
सुदुःखं शयितः पूर्वं प्राप्येदं सुख मुत्तमम् ।
प्राप्तकालं न जानीते विश्वामित्रो यथामुनिः ॥ ६
घृताच्यांकिलसंसक्तो दशवर्षाणि लक्ष्मण! ।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ ७

सहि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किंपुनर्यः पृथग्जनः ॥ ८
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ! ।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ ९
नच रोषवशं तात ! तं त्व मर्हसि लक्ष्मण ! ।
निश्चयार्थं मविज्ञाय सहसा प्राकृतो यथा ॥ १०
सत्त्वयुक्ताहि पुरुषा स्त्वद्विधाः पुरुषर्षभ ! ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११
प्रसादये त्वां धर्मज्ञ ! सुग्रीवार्थे समाहिता ।
महान्रोषस्समुत्पन्न स्तं रम्भस्त्यज्यता मयम् ॥ १२
रुमां मां कपिराज्यं च धनधान्यवसूनि च ।
रामप्रियार्थं सुग्रीव स्त्यजे दिति मतिर्मम ॥ १३
समानेष्यति सुग्रीव स्सीतया सह राघवम् ।
शशाङ्क मिव रोहिण्या निहत्वा रावणं रणे ॥ १४
शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ १५
अहत्वा तांश्च दुर्धर्षा न्राक्षसान्कामरूपिणः ।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६
तेन शक्या रणे हन्तु मसहायेन लक्ष्मण ! ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥" १७
एव माख्यातवा न्वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मेव्यक्तश्रुवात्तस्माद्भवी म्यहम् ॥ १८

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः ।
आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् ॥ १९
तांश्च प्रतीक्षमाणोऽयं विक्रान्तां त्सुमहाबलान् ।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ २०
कृता तु संस्था सौमित्रे ! सुग्रीवेण यथा पुरा ।
अद्यतै र्वानरै स्सर्वै रागन्तव्यं महाबलैः ॥ २१
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।
अद्य त्वामुपयास्यन्ति जहि कोप मरिन्दम ! ॥ २२
कोट्योऽनेकास्तु काकुत्स्थ ! कपीनां दीप्ततेजसाम् ।
तव हि मुख मिदं निरीक्ष्य कोपा त्क्षतजनिभे नयने निरीक्षमाणाः ।
हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्कितास्तु सर्वाः ॥

इति श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशस्सर्गः ॥

॥ षट्त्रिंशस्सर्गः ॥

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।
मृदुस्वभाव स्सौमित्रिः प्रतिजग्राह तद्वचः ॥ १
तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्न मिवात्यजत् ॥ २
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।
चिच्छेद विमद श्चासी त्सुग्रीवो वानरेश्वरः ॥ ३
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीव स्संप्रहर्षयन् ॥ ४

"प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
रामप्रसादात्सौमित्रे! पुनः प्राप्तमिदं मया ॥ ५
कश्शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
तादृशं विक्रमं वीर! प्रतिकर्तुमरिन्दम! ॥ ६
सीतां प्राप्स्यति धर्मात्मा वधिष्यतिच रावणम् ।
सहायमात्रेण मया राघवस्स्वेन तेजसा ॥ ७
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ।
शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥ ८
धनुर्विष्फारयाम्रस्य यस्य शब्देन लक्ष्मण! ।
सशैला कम्पिता भूमि स्सहायै स्तस्य किन्नु वै ॥ ९
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ! ।
गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम् ॥ १०
यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥" ११
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैव मुवाच ह ॥ १२
"सर्वथा हि मम भ्राता सनाथो वानरेश्वर! ।
त्वया नाथेन सुग्रीव! प्रश्रितेन विशेषतः ॥ १३
यस्ते प्रभाव स्सुग्रीव! यच्च ते शौच मार्जवम् ।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तु मनुत्तमाम् ॥ १४
सहायेन च सुग्रीव! त्वया रामः प्रतापवान् ।
वधिष्यति रणे शत्रूनचिरा न्नात्र संशयः ॥ १५

धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः ।
उपपन्नं च युक्तं च सुग्रीव! तव भाषितम् ॥ १६
दोषज्ञ स्सतिसामर्थ्ये कोऽन्यो भाषितु मर्हति ।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम! ॥ १७
सदृश श्चासि रामस्य विक्रमेण बलेन च ।
सहायो दैवतैर्दत्त श्चिराय हरिपुङ्गव! ॥ १८
किंतु शीघ्र मितो वीर! निष्क्राम त्वं मया सह ।
सान्त्वयस्व वयस्यं त्वं भार्याहरणकर्शितम् ॥ १९
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
मया त्वं परुषाण्युक्त स्तच्च त्वं क्षन्तु मर्हसि ॥" २०

इति श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशस्सर्गः ॥

॥ सप्तत्रिंशस्सर्गः ॥

एव मुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनूमन्तं स्थितं पार्श्वे सचिवं त्विद मब्रवीत् ॥ १
"महेन्द्र हिमवद्विन्ध्य कैलासशिखरेषु च ।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २
तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः ।
पर्वतेषु समुद्रान्ते पश्चिमायां च ये दिशि ॥ ३
आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ।
पद्मताळवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४

अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः ।
अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ ५
मनश्शिलागुहावासा वानराः कनकप्रभाः ।
मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ६
तरुणादित्यवर्णाश्च पर्वते च महारुणे ।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ ७
वनेषु च सुरम्येषु सुगन्धिषु महत्सुच ।
तापसानांच रम्येषु वनान्तेषु समन्ततः ॥ ८
तांस्तां स्समानय क्षिप्रं पृथिव्यां सर्ववानरान् ।
सामदानादिभि स्सर्वै राशु प्रेषयवानरान् ॥ ९
प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं हरींस्संप्रेषयापरान् ॥ १०
ये प्रसक्ताश्च कामेषु दीर्घसूत्रा श्च वानराः ।
इहानयस्व तांस्सर्वान् शीघ्रं तु ममशासनात् ॥ ११
अहोभि र्दशभि र्ये च नागच्छन्ति ममाज्ञया ।
हन्तव्या स्ते दुरात्मानो राजशासनदूषकाः ॥ १२
शतान्यथ सहस्राणां कोट्य श्च मम शासनात् ।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ १३
मेघपर्वतसंकाशा इछादयन्त इवाम्बरम् ।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासना दितः ॥ १४
ते गतिज्ञा गतिं ज्ञात्वा पृथिव्यां सर्ववानराः ।
आनयन्तु हरीं स्सर्वां स्त्वरिता इशासनान्मम ॥ " १५

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् ॥ १६
ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरय स्तत्क्षणेन वै ॥ १७
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।
वानरावानरांत्सर्वा न्नामहेतोरचोदयन् ॥ १८
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।
सुग्रीवस्याऽययु श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९
तत स्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ।
तिस्रः कोट्यः प्लवङ्गानां निर्ययु र्यत्र राघवः ॥ २०
अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः ।
तप्तहेम महाभास स्तस्मात्कोट्यो दश च्युताः ॥ २१
कैलासशिखरेभ्य श्च सिंहकेसरवर्चसाम् ।
ततःकोटिसहस्राणि वानराणामुपागमन् ॥ २२
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३
अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।
विन्ध्या द्वानरकोटीनां सहस्रान्यपतन्द्रुतम् ॥ २४
क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेळाशनाश्चैव तेषां संख्या न विद्यते ॥ २५
वनेभ्यो गह्वरेभ्य श्च सरिद्भ्य श्च महाजवा ।
आगच्छ द्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६

ये तु त्वरयितुं याता वानरा स्सर्ववानरान् ।
ते वीरा हिमवच्छैलं ददृशु स्तं महाद्रुमम् ॥ २७

तस्मिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ २८

अन्ननिष्यन्दजातानि मूलानि च फलानि च ।
अमृतास्वादकल्पानि ददृशु स्तत्र वानराः ॥ २९

तदन्नसंभवं दिव्यंफलंमूलं मनोहरम् ।
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ ३०

तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ ३१

तस्माच्च यज्ञायतना त्पुष्पाणि सुरभीणि च ।
आनिन्यु र्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
संचोदयित्वा त्वरिता यूथानां जग्मु रग्रतः ॥ ३३

ते तु तेनमुहूर्तेन यूथपा श्शीघ्रगामिनः ।
किष्किन्धां त्वरया प्राप्ता स्सुग्रीवो यत्र वानरः ॥ ३४

ते गृहीत्वौषधी स्सर्वाः फलं मूलं च वानराः ।
"तं प्रतिग्राहयामासु र्वचनं चेद मब्रुवन् ॥ ३५

सर्वे परिगताश्शैलास्समुद्राश्च वनानि च ।
पृथिव्यां वानरा स्सर्वे शासना दुपयान्ति ते ॥" ६६

एवं श्रुत्वा ततो हृष्ट स्सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह तत्प्रीत स्तेषां सर्वमुपायनम् ॥ ३७

इति श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशस्सर्गः ॥

॥ अष्टत्रिंशस्सर्गः ॥

प्रतिगृह्य च तत्सर्वं मुपायन मुपाहृतम् ।
वानरां स्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १

विसर्जयित्वा स हरीन् शूरां स्तान्कृतकर्मणः ।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् ॥ ३

किष्किन्धाया विनिष्क्राम यदि ते सौम्य! रोचते ।"
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ ४

सुग्रीवः परमप्रीतो वाक्य मेतदुवाच ह ।
"एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥" ५

तमेव मुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ।
विसर्जयामास तदा तारा मन्याश्च योषितः ॥ ६

एतेत्युचै र्हरिवरा न्सुग्रीव स्समुदाहरत् ।
तस्य तद्वचनं श्रुत्वा हरय श्शीघ्र मायययुः ॥ ७

बद्धाञ्जलिपुटा स्सर्वे ये स्युः स्त्रीदर्शनक्षमाः ।
तानुवाच ततः प्राप्ता न्राजाऽर्कसदृशप्रभः ॥ ८

"उपस्थापयत क्षिप्रं शिबिकां मम वानराः ।"
श्रुत्वा तु वचनं तस्य हरय श्शीघ्रविक्रमाः ॥ ९

समुपस्थापयामासु श्शिबिकां प्रियदर्शनाम् ।
ता मुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥ १०

'लक्ष्मण! ऽरुह्यतां शीघ्र' मिति सौमित्रिमब्रवीत् ।
इत्युक्त्वा काञ्चनं यानं सुग्रीव स्सूर्यसन्निभम् ॥ ११
बृहद्भि र्हरिभि र्युक्त मारुरोह सलक्ष्मणः ।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ १२
शुक्लैश्च वालव्यजनै र्धूयमानै स्समन्ततः ।
शङ्खभेरीनिनादैश्च हरिभि श्चाभिनन्दितः ॥ १३
निर्ययौ प्राप्य सुग्रीवो राज्यश्रिय मनुत्तमाम् ।
सवानरशतै स्तीक्ष्णैर्बहुभि श्शस्त्रपाणिभिः ॥ १४
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।
सतं देश मनुप्राप्य श्रेष्ठं रामनिषेवितम् ॥ १५
अवातरन्महातेजा श्शिबिकाया स्सलक्ष्मणः ।
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ॥ १६
कृताञ्जलौ स्थिते तस्मिन्वानरा श्चाभवं स्तथा ।
[उद्धृताञ्जलिपद्मास्ते सुग्रीवस्य समन्ततः ॥] १७
तटाकमिव तद्दृष्ट्वा रामः कुट्मलपङ्कजम् ।
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १८
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥ १९
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ।
तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ २०
"धर्ममर्थं च कामंच यस्तु काले निषेवते ।
विभज्य सततं वीर! सराजा हरिसत्तम! ॥ २१

हित्वा धर्मं तथार्थंच कामं यस्तु निषेवते ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ २२
अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २३
उद्योगसमयस्त्वेष प्राप्त इशत्रुविनाशन ! ।
संचिन्त्यतां हि पिङ्गेश ! हरिभिस्सह मन्त्रिभिः ॥" २४
एव मुक्तस्तु सुग्रीवो रामं वचन मब्रवीत् ।
"प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ॥ २५
त्वत्प्रसादा न्महाबाहो ! पुनः प्राप्तमिदं मया ।
तवदेव ! प्रसादाच्च भ्रातुश्च जयतांवर ! ॥ २६
कृतं नप्रतिकुर्याद्यः पुरुषाणां सदूषकः ।
एते वानरमुख्याश्च शतशइशत्रुसूदन ! ॥ २७
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ।
ऋक्षाश्चवाहिता इशूरा गोलाङ्गूलाश्च राघव ! ॥ २८
कान्तारवनदुर्गाणा मभिज्ञा घोरदर्शनाः ।
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ॥ २९
स्वैस्स्वैः परिवृता स्सैन्यै र्वर्तन्ते पथि राघव ! ।
शतै इशतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः ॥ ३०
अयुतै श्चावृता वीरा इशङ्कुभिश्च परन्तप ! ।
अर्बुदै रर्बुदशतै र्मध्यै श्चान्तैश्च वानराः ॥ ३१
समुद्रैश्च पराधैश्च हरयो हरियूथपाः ।
आगमिष्यन्ति ते राजन् ! महेन्द्रसमविक्रमाः ॥ ३२

मेरुमन्दर संकाशा विन्ध्यमेरुकृतालयाः ।
ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ॥ ३३
निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ।"
ततस्तमुद्योगमवेक्ष्य बुद्धिमान्हरिप्रवीरस्य निदेशवर्तिनः ।
बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३४

इति श्रीमत्किष्किन्धाकाण्डे अष्टत्रिंशस्सर्गः ॥

॥ एकोनचत्वारिंशस्सर्गः ॥

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।
बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १
" यदिन्द्रो वर्षते वर्षं न त चित्रं भवेत्कचित् ।
आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ २
चन्द्रमारश्मिभिः कुर्यात्पृथिवीं सौम्य ! निर्मलाम् ।
त्वद्विधो वाऽपि मित्राणां प्रतिकुर्यात्परन्तप ! ॥ ३
एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य ! शोभनम् ।
जानाम्यहं त्वां सुग्रीव ! सततं प्रियवादिनम् ॥ ४
त्वत्सनाथ स्सखे ! संख्ये जेताऽस्मि सकलानरीन् ।
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तु मर्हसि ॥ ५
जहाराऽत्मविनाशाय वैदेहीं राक्षसाधमः ।
वञ्चयित्वा तु पौलोमी मनुह्लादो यथा शचीम् ॥ ६
नचिरात्तं हनिष्यामि रावणं निशितै श्शरैः ।
पौलोम्याः पितरं दृप्तं शतक्रतु रिवाऽहवे ॥ " ७

एतस्मिन्नन्तरे चैव रज स्समभिवर्तत ।
उष्णां तीव्रां सहस्रांशो श्छादय द्गगने प्रभाम् ॥ ८
दिशः पर्याकुला श्रास न्रजसा तेन मूर्छता ।
चचाल च मही सर्वा सशैलवनकानना ॥ ९
ततो नगेन्द्रसंकाशै स्तीक्ष्णदंष्ट्रै र्महाबलैः ।
कृत्स्ना संछादिता भूमि रसंख्येयैः प्लवङ्गमैः ॥ १०
निमेषान्तरमात्रेण तत स्तैर्हरियूथपैः ।
कोटीशतपरीवारैः कामरूपिभिरावृता ॥ ११
नादेयैःपार्वतीयै श्च सामुद्रै श्च महाबलैः ।
हरिभि र्मेघ निर्ह्रादै रन्यै श्च वनचारिभिः ॥ १२
तरुणादित्यवर्णै श्च शशिगौरैश्च वानरैः ।
पद्मकेसरवर्णै श्च श्वेतै र्मेरुकृतालयैः ॥ १३
कोटीसहस्रै र्दशभिः श्रीमान्परिवृतस्तदा ।
वीर श्शतबलि र्नाम वानरः प्रत्यदृश्यत ॥ १४
ततः काञ्चनशैलाभ स्तारायाः वीर्यवा न्पिता ।
अनेकै र्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ १५
तथा परेण कोटीनां सहस्रेण समन्वितः ।
पिता रुमाया स्संप्राप्त स्सुग्रीवश्वशुरो विभुः ॥ १६
पद्मकेसरसंकाश स्तरुणार्कनिभाननः ।
बुद्धिमान्वानरश्रेष्ठ स्सर्ववानरसत्तमः ॥ १७
अनीकै र्बहुसाहस्रै र्वानराणां समन्वितः ।
पिता हनुमतश्श्रीमान्केसरी प्रत्यदृश्यत ॥ १८

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः ।
वृतः कोटिसहस्रेण वानराणा मदृश्यत ॥ १९

ऋक्षाणां भीमवेगानां धूम्रश्शत्रुनिबर्हणः ।
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ २०

महाचलनिभै र्घोरैः पनसो नाम यूथपः ।
आजगाम महावीर्य स्तिसृभिः कोटिभि र्वृतः ॥ २१

नीलाञ्जनचयाकारो नीलो नामाऽथ यूथपः ।
अदृश्यत महाकायः कोटिभि र्दशभि वृतः ॥ २२

ततः काञ्चनशैलाभो गवयोनाम यूथपः ।
आजगाम महावीर्यः पञ्चभिः कोटिभिर्वृतः ॥ २३

दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा ।
वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ २४

मैन्द श्च द्विविद श्चोभावश्विपुत्रौ महाबलौ ।
कोटिकोटिसहस्रेण वानराणा मदृश्यताम् ॥ २५

गज श्च बलवा न्वीरः कोटिभि स्तिसृभि वृतः ।
आजगाम महातेजा स्सुग्रीवस्य समीपतः ।
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः ॥ २६

कोटिभि र्दशभिः प्राप्त स्सुग्रीवस्य वशे स्थितः ।
रुमण्वा न्नाम विक्रान्तो वानरो वानरेश्वरम् ॥ २७

आययौ बलवां स्तूर्णं कोटी शतसमावृतः ।
ततः कोटिसहस्राणां सहस्रेण शतेन च ॥ २८

पृष्ठतोऽनुगतःप्राप्तो हरिभि र्गन्धमादनः ।
ततः पद्मसहस्रेण वृत श्शङ्कुशतेन च ॥ २९
युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ।
तत स्तारासुतः स्तारो हरि र्भीमपराक्रमः ॥ ३०
पञ्चभि र्हरिकोटीभि र्दूरतः प्रत्यदृश्यत ।
इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ॥ ३१
एकादशानां कोटीना मीश्वर स्तै स्समावृतः ।
ततो रम्भ स्त्वनुप्राप्त स्तरुणादित्यसन्निभः ॥ ३२
अयुतेनावृत श्चैव सहस्रेण शतेन च ।
ततो यूथपति र्वीरो दुर्मुखो नाम वानरः । ३३
प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो वली ।
कैलासशिखराकारै र्वानरै र्भीमविक्रमैः ॥ ३४
वृतः कोटीसहस्रेण हनूमा न्प्रत्यदृश्यत ।
नळ श्चापि महावीर्य स्संवृतो द्रुमवासिभिः ॥ ३५
कोटीशतेन संप्राप्त स्सहस्रेण शतेन च ।
ततो दधिमुख श्श्रीमान्कोटिभि र्दशभि र्वृतः ॥ ३६
संप्राप्तोऽभिमत स्तस्य सुग्रीवस्य महात्मनः ।
शरभः कुमुदो वह्नि र्वानरो रंह एवच ॥ ३७
एतेचान्येच बहवो वानराः कामरूपिणः ।
आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ॥ ३८
यूथपा स्समनुप्राप्ता स्तेषां संख्या न विद्यते ।
आगताश्च विशिष्टा श्च पृथिव्यां सर्ववानराः ॥ ३९

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ४०
कुर्वाणा बहुशब्दां श्च प्रहृष्टा बाहुशालिनः ।
शिरोभि र्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ४१
अपरे वानरश्रेष्ठा स्संयम्यच यथोचितम् ।
सुग्रीवेण समागम्य स्थिताः प्राञ्जलय स्तदा ॥ ४२
सुग्रीव स्त्वरितो रामे सर्वां स्तान्वानरर्षभान् ।
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलि रब्रवीत् ॥ ४३
"यथासुखंपर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ।
निवेशयित्वा विधिव द्बलानि बलं बलज्ञःप्रतिपत्तुमीष्टे ॥" ४४

इति श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशस्सर्गः ॥

॥ चत्वारिंशस्सर्गः ॥

अथ राजा समृद्धार्थ स्सुग्रीवः प्लवगेश्वरः ।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥ १
"आगता विनिविष्टा श्च बलिनः कामरूपिणः ।
वानरावारणेन्द्राभा ये मद्विषयवासिनः ॥ २
त इमे बहुविक्रान्तै र्हरिभि र्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ ३
ख्यातकर्मापदाना श्च बलवन्तो जितक्रमाः ।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४

पृथिव्यम्बुचरा राम! नानानगनिवासिनः ।
कोऽयमश इमे प्राप्ता वानरास्तव किंकिराः ॥ ५
निदेशवर्तिन स्सर्वे सर्वे गुरुहिते रताः ।
अभिप्रेत मनुज्ञातुं तव शक्ष्यन्त्यरिन्दम! ॥ ६
त इमे बहुसाहस्रै रनीकै र्भीमविक्रमैः ।
यन्मन्यसेनरव्याघ्र! प्राप्तकालं तदुच्यताम् ॥ ७
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ।
काम मेषा मिदं कार्यं विदितं मम तत्त्वतः ॥ ८
तथापि तु यथातत्त्व माज्ञापयितु मर्हसि ॥"
इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ॥ ९
बाहुभ्यां संपरिष्वज्य इदं वचन मब्रवीत् ।
"ज्ञायतां मम वैदेही यदि जीवति वा नवा ॥ १०
सच देशो महाप्राज्ञ! यस्मि न्वसति रावणः ।
अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ ११
प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ।
नाह मस्मिन् प्रभुःकार्ये वानरेश! न लक्ष्मणः ॥ १२
त्व मस्य हेतुः कार्यस्य प्रभु श्च प्लवगेश्वर! ।
त्व मेवाऽज्ञापय विभो! मम कार्यविनिश्चयम् ॥ १३
त्वं हि जानासि यत्कार्यं मम वीर! नसंशयः ।
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ॥ १४
भवानस्मद्धिते युक्त स्सुकृतार्थोऽर्थवित्तमः ।"
एव मुक्त स्तु सुग्रीवो विनतं नाम यूथपम् ॥ १५

अब्रवी द्रामसान्निध्ये लक्ष्मणस्य च धीमतः ।
शैलाभं मेघनिर्घोष मूर्जितं प्लवगेश्वरः ॥ १६
सोमसूर्यौ[illegible] स्सार्धं वानरै र्वानरोत्तम ! । निभै
देशकालनयै र्युक्तः कार्याकार्यविनिश्चये ॥ १७
वृत इशतसहस्रेण वानराणां तरस्विनाम् ।
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ १८
तत्र सीतांच वैदेहीं निलयं रावणस्यच ।
मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ १९
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।
काळिन्दीं यमुनां रम्यां यामुनंच महागिरिम् ॥ २०
सरस्वतीं च सिन्धुंच शोणं मणिनिभोदकम् ।
महीं कालमहींचैव शैलकाननशोभिताम् ॥ २१
ब्रह्ममालान्विदेहांश्च माळवान्काशिकोसलान् ।
मागधांश्च महाग्रामा न्पुण्ड्रान्वङ्गांस्तथैव च ॥ २२
पत्तनं कोशकाराणां भूमिं च रजताकराम् ।
सर्वं मेत द्विचेतव्यं मृगयद्भिस्ततस्ततः ॥ २३
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ।
समुद्रमवगाढांश्च पर्वतान्पत्तनानि च ॥ २४
मन्दरस्यच ये कोटिं संश्रिताः केचिदायताम् ।
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ॥ २५
घोरा लोहमुखा श्चैव जवनाश्चैकपादकाः ।
अक्षया बलवन्त श्च पुरुषाः पुरुषादकाः ॥ २६

किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ।
आममीनाशनास्तत्र किराता द्वीपवासिनः ॥ २७
अन्तर्जलचराघोरा नरव्याघ्रा इति श्रुताः ।
एतेषा मालयास्सर्वे विषेयाः काननौकसः ॥ २८
गिरिभि र्यै च गम्यन्ते प्लवनेन प्लवेन च ।
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ २९
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ।
यवद्वीप मतिक्रम्य शिशिरो नाम पर्वतः ॥ ३०
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ।
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ॥ ३१
मार्गध्वं सहितास्सर्वे रामपत्नीं यशस्विनीम् ।
ततो रक्तजलं शोण मगाधं शीघ्रगामिनम् ॥ ३२
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ।
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ॥ ३३
रावण स्सह वैदेह्या मार्गितव्य स्ततस्ततः ।
पर्वतप्रभवा नद्य स्सुरम्या बहुनिष्कुटाः ॥ ३४
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ।
तत स्समुद्र द्वीपांश्च सुभीमान्द्रष्टु मर्हथ ॥ ३५
ऊर्मिमन्तं समुद्रं च क्रोशन्त मनिलोद्धतम् ।
तत्रासुरा महाकाया इछायां गृह्णन्ति नित्यशः ॥ ३६
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ।
तं कालमेघ प्रतिमं महोरगनिषेवितम् ॥ ३७

अभिगम्य महानादं तीर्थेनैव महोदधिम् ।
ततो रक्तजलं भीमं लोहितं नाम सागरम् ॥ ३८
गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ।
गृहं च वैनतेयस्य नानारत्न विभूषितम् ॥ ३९
तत्र कैलाससंकाशं विहितं विश्वकर्मणा ।
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ॥ ४०
शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ।
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ॥ ४१
निहता ब्रह्मतेजोभि रहन्यहनि राक्षसाः ।
अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः ॥ ४२
ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् ।
गता द्रक्ष्यथ दुर्धर्षा मुक्ताहार मिवोर्मिभिः ॥ ४३
तस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः ।
दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः ॥ ४४
सरश्च राजतैः पद्मै र्ज्वलितै र्हेमकेसरैः ।
नाम्ना सुदर्शनं नाम राजहंसै स्समाकुलम् ॥ ४५
विबुधा श्चारणा यक्षाः किन्नरा स्साप्सरोगणाः ।
हृष्टा स्समभिगच्छन्ति नळिनीं तां रिरंसवः ॥ ४६
क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः ! ।
जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ ४७
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ।
अस्याहु स्तन्महावेग मोदनं सचराचरम् ॥ ४८

तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ।
श्रूयते च समर्थानां दृष्ट्वा तद्वडवामुखम् ॥ ४९
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ।
जातरूपशिलो नाम महान्कनकपर्वतः ॥ ५०
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ।
पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ! ॥ ५१
आसीनं पर्वतस्याग्रे सर्वभूत नमस्कृतम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ५२
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ५३
पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः ।
ततः परं हेममयश्श्रीमानुदयपर्वतः ॥ ५४
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ।
जातरूपमयी दिव्या विराजति सवेदिका ॥ ५५
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ।
जातरूपमयैर्दिव्यैश्शोभते सूर्यसन्निभैः ॥ ५६
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५७
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ५८
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५९

तत्र वैखानसा नाम वालखिल्या महर्षयः ।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ६०
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।
यस्मिं स्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ६१
शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च ।
रावणस्सह वैदेह्या मार्गितव्यस्तत स्ततः ॥ ६२
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ।
आविष्टा तेजसा संध्या पूर्वारक्ता प्रकाशते ॥ ६३
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ।
सूर्यस्योदयनं चैव पूर्वाह्येषा दिगुच्यते ॥ ६४
तस्यशैलस्य पृष्ठेषु निर्झरेषु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६५
ततः परमगम्यास्याद्दिक्पूर्वा त्रिदशावृता ।
रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ ६६
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ।
येच नोक्ता मया देशा विचेया तेषु जानकी ॥ ६७
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः ! ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ ६८
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६९
ऊर्ध्वं मासान्नवस्तव्यं वसन्वध्यो भवेन्मम ।
सिद्धार्थास्सान्निवर्तध्वमधिगम्य तु मैथिलीम् ॥ ७०

महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः ! ।
अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्तास्सुखिनो भविष्यथ ॥

इति श्रीमत्किष्किन्धाकाण्डे चत्वारिंशस्सर्गः ॥

॥ एकचत्वारिंशस्सर्गः ॥

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ १

नीलमग्निसुतं चैव हनूमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ २

सुहोत्रं च शरारिंच शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ ३

मैन्दंच द्विविदं चैव विजयं गन्धमादनम् ।
उल्कामुखमसङ्गंच हुताशनसुतावुभौ ॥ ४

अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ।
वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥ ५

तेषामग्रेसरं चैव महद्बल मसङ्गंच (पा. टु)
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ ६

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ ७

"सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥ ८

ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ॥ ९
मेखलामुत्कलां चैव दशार्णनगराण्यपि ।
अश्ववन्तीमवन्तींच सर्वमेवानुपश्यत ॥ १०
विदर्भानृषिकां श्चैव रम्यान्माहिषकानपि ।
तथा वङ्गान् कळिङ्गांश्च कौशिकांश्च समन्ततः ॥ ११
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥ १२
तथैवान्ध्रांश्च पुण्ड्रांश्च चोळान्पाण्ड्यांस्सकेरळान् ।
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥ १३
विचित्रशिखरश्रीमांश्चित्रपुष्पितकाननः ।
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ १४
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।
तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ १५
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ १६
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ १७
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी ।
कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ! ॥ १९

ततस्समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २०
चित्रनानानगश्रीमान्महेन्द्रः पर्वतोत्तमः ।
जातरूपमयश्रीमानवगाढो महार्णवम् ॥ २१
नानाविधैर्नगैस्सर्वैर्लताभिश्चोपशोभितम् ।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२
सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ।
तमुपैति सहस्राक्षस्सदा पर्वसु पर्वसु ॥ २३
द्वीपस्तस्यापरे पारे शतयोजनमायतः ।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ॥ २४
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ।
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ॥ २५
राक्षसाधिपतेर्वासस्सहस्राक्षसमद्युतेः ।
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ॥ २६
अङ्गारकेति विख्याता छायामाकृष्य भोजिनी ।
एषा निस्संशयान्कृत्वा संशयान्नष्टसंशयाः ॥ २७
मृगयध्वं नरेन्द्रस्य पत्नीमिततेजसः ।
तमतिक्रम्य लक्ष्मीवांत्समुद्रे शतयोजने ॥ २८
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ।
चन्द्रसूर्याग्निसंकाशस्सागराम्बुसमावृतः ॥ २९
भ्राजते विपुलैश्शृङ्गैरम्बरं विलिखन्निव ।
तस्यैकं काञ्चनं शृङ्गं सेवतेऽयं निशाकरः ॥ ३०

श्वेतं राजतमेकं च सेवतेऽयं दिवाकरः ।
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ ३१
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ! ।
तमतिक्रम्य दुर्धर्षा स्सूर्यवा न्नाम पर्वतः ॥ ३२
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥ ३३
सर्वकामफलै र्वृक्षै स्सर्वकालमनोहरैः ।
तत्र भुक्त्वा वराहाणि मूलानि च पलानि च ॥ ३४
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ! ।
तत्र नेत्र मनः कान्तः कुञ्जरो नाम पर्वतः ॥ ३५
अगस्त्य भवनं यत्र निर्मितं विश्वकर्मणा ।
तत्रयोजनविस्तार मुच्छ्रितं दशयोजनम् ॥ ३६
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ।
तत्र भोगवती नाम सर्पाणामालयः पुरी ॥ ३७
विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगै र्घोरै स्तीक्ष्णदंष्ट्रै र्महाविषैः ॥ ३८
सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ३९
तत्र चानन्तरा देशा ये केचन सुसंवृताः ।
तंच देशमतिक्रम्य महानृषभसंस्थितः ॥ ४०
सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ॥ ४१

दिव्य मुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ।
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ॥ ४२
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ।
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥ ४३
शैलूषो ग्रामणी श्शिग्रुश्शुभ्रो बभ्रुस्तथैव च ।
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ॥ ४४
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।
ततः परं न वस्सेव्यः पितृलोकस्सुदारुणः ॥ ४५
राजधानी यमस्यैषा कष्टेन तमसा वृता ।
एतावदेव युष्माभि र्वीरा! वानरपुङ्गवाः! ॥ ४६
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ।
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ॥ ४७
गतिं विदित्वा वैदेह्यास्सन्निवर्तितुमर्हथ ।
यस्तु मासान्निवृत्तोऽग्रे 'दृष्टासी' तेति वक्ष्यति ॥ ४८
मत्तुल्यविभवो भोगै स्सुखं स विहरिष्यति ।
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ॥ ४९
कृतापराधो बहुशो मम बन्धुर्भविष्यति ।
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥"

इति श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशस्सर्गः ॥

॥ द्विचत्वारिंशस्सर्गः ॥

अथ प्रस्थाप्य सुग्रीव स्तान्हरीन्दक्षिणां दिशम् ।
अब्रवी न्मेघसंकाशं सुषेणं नाम यूथपम् ॥ १

तारायाः पितरं राजाश्वशुरंभीमविक्रमम् ।
अब्रवी त्प्राञ्जलि र्वाक्य मभिगम्य प्रणम्य च ॥ २

मरीचपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ।
वृतं कपिप्रवरै श्शूरै र्मेहेन्द्रसदृशद्युतिम् ॥ ३

बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् ।
मरीचिपुत्रा न्मारीचा नर्चिर्मालिं न्महाबलान् ॥ ४

ऋषिपुत्रां श्च तां त्सर्वान्प्रतीचीमादिशद्दिशम् ।
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ! ॥ ५

सुषेण प्रमुखा यूयं वैदेहीं परिमार्गत ।
सुराष्ट्रांस्सह बाह्लीकान् शूरान्भीरां स्तथैव च ॥ ६

स्फीतान्जनपदान्रम्या न्विपुलानि पुराणि च ।
पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् ॥ ७

तथा केतकषण्डां श्च मार्गध्वं हरियूथपाः ! ।
प्रत्यक्स्रोतोगमाश्चैव नद्य श्शीतजलाश्शिवाः ॥ ८

तापसानामरण्यानि कान्तारा गिरय श्च ये ।
तत स्स्थलीं मरुप्राया मत्युच्चाशिरस श्शिलाः ॥ ९

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।
ततः पश्चिम मासाद्य समुद्रं द्रष्टुमर्हथ ॥ १०

कुल
तिमिनक्राकुलजल मक्षोभ्य मथ वानराः ! ।
ततः केतकषण्डेषु तमालगहनेषु च ॥ ११
कपयो विहरिष्यन्ति नारिकेलवनेषु च ।
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ॥ १२
वेलातटनिविष्टेषु पर्वतेषु वनेषु च ।
मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् ॥ १३
अवन्ती मङ्गलोपां च तथा चालक्षितं वनम् ।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ १४
सिन्धुसागरयो श्चैव सङ्गमे तत्र पर्वतः ।
महान्हेमगिरि र्नाम शतशृङ्गो महाद्रुमः ॥ १५
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षिगमाः स्थिताः ।
तिमिमत्स्यगजां श्चैव नीडा न्यारोपयन्ति ये ॥ १६
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।
दृप्ता स्तृषा श्च मातङ्गा स्तोयदस्वननिस्वनाः ॥ १७
विचरन्ति विशालेऽस्मिन्स्तोयपूर्णे सनन्ततः ।
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ॥ १८
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ।
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् ॥ १९
दुर्दर्शां पारियात्रस्य गता द्रक्ष्यथ वानराः ! ।
कोट्यं स्तत्र चतुर्विंश द्गन्धर्वाणां तरस्विनाम् ॥ २०
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ।
पावकार्चिःप्रतीकाशा स्समवेता स्सहस्रशः ॥ २१

नात्यासादयितव्या स्ते वानरै र्भीमविक्रमैः ॥
नादेयं च फलं तस्माद्देशात्किंचित् प्लवङ्गमैः ॥ २२
दुरासदा हि ते वीरा स्सत्त्ववन्तो महाबलाः ।
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ २३
तत्र यत्नश्च कर्तव्यो मार्गितव्याच जानकी ।
नहि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥ २४
तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः ।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ २५
श्रीमां त्समुदित स्तत्र योजनानां शतं समम् ।
गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः ! ॥ २६
चतुर्भागे समुद्रस्य चक्रवा न्नाम पर्वतः ।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ २७
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ २८
तस्य सानुषु चित्रेषु विशालासु गुहासु च ।
रावण स्सह वैदेह्या मार्गितव्य स्ततस्ततः ॥ २९
योजनानां ततष्षष्टि र्वराहो नाम पर्वतः ।
सुवर्णशृङ्ग स्सुश्रीमा नगाधे वरुणालये ॥ ३०
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।
यस्मि न्वसति दुष्टात्मा नरको नाम दानवः ॥ ३१
तत्र सानुषु चित्रेषु विशालासु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्य स्ततस्ततः ॥ ३२

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।
पर्वतस्सर्वसौवर्णो धारा प्रस्रवणायुतः ॥ ३३
तं गजा श्च वराहा श्च सिंहव्याघ्रा श्च सर्वतः ।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ ३४
यस्मिन्हरिहयश्रीमान्महेन्द्रः पाकशासनः ।
अभिषिक्तस्सुरैराजामेघवान्नाम पर्वतः ॥ ३५
त मतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।
षष्टि र्गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ३६
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयै र्वृक्षै श्शोभितानि सुपुष्पितैः ॥ ३७
तेषां मध्ये स्थितो राजा मेरु रुत्तरपर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ३८
तेनैवमुक्त श्शैलेन्द्र स्सर्व एव त्वदाश्रयाः ।
मत्प्रसादा द्भविष्यन्ति दिवारात्रं च काञ्चनाः ॥ ३९
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।
ते भविष्यन्ति रक्ता श्च प्रभया काञ्चनप्रभाः ॥ ४०
विश्वेदेवा श्च मरुतो वसव श्च दिवौकसः ।
आगम्य पश्चिमां सन्ध्यां मेरु मुत्तमपर्वतम् ॥ ४१
आदित्य मुपतिष्ठन्ति तै श्च सूर्योऽभिपूजितः ।
अदृश्य स्सर्वभूताना मस्तं गच्छति पर्वतम् ॥ ४२
योजनानां सहस्राणि दश तानि दिवाकरः ।
मुहूर्ताधेन तं शीघ्र मभियाति शिलोच्चयम् ॥ ४३

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम् ।
प्रासादगणसंबाधं विहितं विश्वकर्मणा ॥ ४४
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ ४५
अन्तरा मेरुमस्तं च तालोदकशिरा महान् ।
जातरूपमयश्रीमान्भ्राजते चित्रवेदिकः ॥ ४६
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४७
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः ।
मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ ४८
प्रष्टव्यो मेरुसावर्णिर्महर्षिस्सूर्यसन्निभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ ४९
एतावज्जीवलोकस्य भास्करो रजनीक्षये ।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ ५०
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः ! ।
अभास्करमर्यादं न जानीमस्ततःपरम् ॥ ५१
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
अस्तपर्वतमासाद्य पूर्णे मासे निवर्तत ॥ ५२
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ।
सहैव शूरो युष्माभिश्श्वशुरो मे गमिष्यति ॥ ५३
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ।
गुरुरेष महाबाहुश्श्वशुरो मे महाबलः ॥ ५४

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥ ५५
[भवन्तः परिपश्यन्तु यथा दृश्येत जानकी] ।
दृष्टायां तु नरेन्द्रस्य पत्न्यामिततेजसः ! ॥ ५६
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ।
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत् ॥ ५७
संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ।"
ततस्सुषेणप्रमुखाः प्लवङ्गास्सुग्रीववाक्यं निपुणं निशम्य ।
आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ ५८

इति श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशस्सर्गः ॥

॥ त्रिचत्वारिंशस्सर्गः ॥

ततस्संदिश्य सुग्रीवश्श्वशुरं पश्चिमां दिशम् ।
वीरं शतबलिं नाम वानरं वानरर्षभः ॥ १
उवाच राजा धर्मज्ञस्सर्ववानरसत्तमम् ।
वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २
"वृत इशतसहस्रेण त्वद्विधानां वनौकसाम् ।
वैवस्वतसुतैस्सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ३
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४
अस्मिन्कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ! ॥ ५

कृतं हि प्रियमस्माकं राघवेण महात्मना ।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः ॥ ७
एतां बुद्धिं मवस्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्य मस्मत्प्रियहितैषिभिः ॥ ८
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।
अस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ ९
इमानि वनदुर्गाणि नद्यश्शैलान्तराणि च ।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसंपदा ॥ १०
तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।
प्रस्थलान्भरतां श्चैव कुरूंश्च सह मद्रकैः ॥ ११
काम्भोजान्यवनांश्चैव शकानारट्टकानपि ।
बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ १२
चीनान्परमचीनांश्च नीहारांश्च पुनःपुनः ।
अन्विष्य दरदांश्चैव हिमवन्तं तथैव च ॥ १३
लोध्रपद्मकषण्डेषु देवदारुवनेषु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १४
ततस्सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।
काळं नाम महासानुं पर्वतं तु गमिष्यथ ॥ १५
महत्सु तस्य शैलस्य निर्दरेषु गुहासु च ।
विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ १६

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।
ततस्सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ १७
ततो देवसखो नाम पर्वतः पर्वतालयाः ! ।
नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ १८
तस्य काननषण्डेषु निर्झरेषु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १९
तमतिक्रम्य चाकाशं सर्वतश्शतयोजनम् ।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ २०
तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।
कैलासं पाण्डुरं शैलं प्राप्य द्रष्टा भविष्यथ ॥ २१
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।
कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ २२
विशाला नलिनी यत्र प्रभूतकमलोत्पला ।
हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ २३
तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।
धनदो रमते श्रीमान्गुह्यकैस्सह यक्षराट् ॥ २४
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २५
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ २६
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ।
देवैरप्यर्चितास्सम्यग्देवरूपा महर्षयः ॥ २७

क्रौञ्चस्य तु गुहाश्चान्यास्सानूनि शिखराणि च ।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २८
क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।
अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २९
न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।
सच सर्वैर्विचेतव्यस्ससानुप्रस्थभूधरः ॥ ३०
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।
मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ ३१
मैनाकस्तु विचेतव्यस्ससानुप्रस्थकन्दरः ।
स्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु ॥ ३२
तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३३
वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः ।
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ ३४
हेमपुष्करसंछन्नं तस्मिन्वैखानसं सरः ।
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ॥ ३५
औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।
गजः पर्येति तं देशं सदा सह करेणुभिः ॥ ३६
तत्सरस्समतिक्रम्य नष्टचन्द्रदिवाकरम् ।
अनक्षत्रगणं व्योम निष्पयोदमनादिमत् ॥ ३७
गभस्तिभिरिवार्कस्य सतु देशः प्रकाशते ।
विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैस्स्वयंप्रभैः ॥ ३८

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ ३९
ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४०
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।
नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः ॥ ४१
रक्तोत्पलवनैश्चात्र मण्डिता श्च हिरण्मयैः ।
तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४२
महार्हमणिवर्णैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलवनैश्चित्रैस्सदेश स्सर्वतो वृतः ॥ ४३
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४४
सर्वरत्नमयैश्चित्रै रवगाढा नगोत्तमैः ।
जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४५
नित्यपुष्पफला स्तत्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसस्पर्शा स्सर्वान्कामांस्स्रवन्ति च ॥ ४६
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।
मुक्तावैडूर्यचित्राणि भूषणानि तथैव च ॥ ४७
स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैवच ।
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ ४८
महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः ।
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ४९

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ।
पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ५०
स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ।
गन्धर्वाः किन्नरा सिद्धा नागाविद्याधरा स्तथा ॥ ५१
रमन्ते सहितास्तत्र नारीभि र्भास्करप्रभाः ।
सर्वे सुकृतकर्माण स्सर्वे रतिपरायणाः ॥ ५२
सर्वे कामार्थसहिता वसन्ति सहयोषितः ।
गीतवादित्रनिर्घोष स्सोत्कृष्टहसितस्वनः ॥ ५३
श्रूयते सततं तत्र सर्वभूतमनोहरः ।
तत्र नामुदितः कश्चिन्नास्ति कश्चि दसत्प्रियः ॥ ५४
अहन्यहनि वर्धन्ते गुणा स्तत्र मनोरमाः ।
समतिक्रम्य तं देश मुत्तरः पयसां निधिः ॥ ५५
तत्र सोमगिरि र्नाम मध्ये हेममयो महान् ।
इन्द्रलोकगता ये च ब्रह्मलोकगता श्च ये ॥ ५६
देवा स्तं समवेक्षन्ते गिरिराजं दिवं गताः ।
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ॥ ५७
सूर्यलक्ष्म्याऽभिविज्ञेय स्तपतेव विवस्वता ।
भगवानपि विश्वात्मा शम्भु रेकादशात्मकः ॥ ५८
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ।
न कथंचन गन्तव्यं कुरूणा मुत्तरेण वः ॥ ५९
अन्येषा मपि भूतानां नातिक्रामति वैगतिः ।
सहि सोमगिरि र्नाम देवाना मपि दुर्गमः ॥ ६०

तमालोक्य ततः क्षिप्र मुपावर्तितु मर्हथ ।
एतावद्वानरै श्शक्यं गन्तुं वानरपुङ्गवाः ! ॥ ६१
अभास्कर ममर्यादं न जानीम स्ततःपरम् ।
सर्व मेत द्विचेतव्यं यन्मया परिकीर्तितम् ॥ ६२
यदन्य दपि नोक्तं च तत्रापि क्रियतां मतिः ।
ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् ।
कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ ६३
ततः कृतार्था स्सहिता स्सबान्धवा मयाऽर्चिता स्सर्वगुणै र्मनोरमैः ।
चरिष्यथोर्वीं प्रति शान्तशत्रव स्सहप्रिया भूतधराः प्लवङ्गमाः ! ॥

इति श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशस्सर्गः ॥

॥ चतुश्चत्वारिंशस्सर्गः ॥

विशेषेण तु सुग्रीवो हनूमत्यर्थ मुक्तवान् ।
स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १
अब्रवीच्च हनूमन्तं विक्रान्त मनिलात्मजम् ।
सुग्रीवः परमप्रीतः प्रभु स्सर्ववनौकसाम् ॥ २
"न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ।
नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ! ॥ ३
साऽसुरा स्सहगन्धर्वा स्सनागनरदेवताः ।
विदिता स्सर्वलोकास्ते ससागरधराधराः ॥ ४
गति र्वेग श्च तेज श्च लाघवं च महाकपे ! ।
पितु स्ते सदृशं वीर ! मारुतस्य महौजसः ॥ ५

तेजसा वापि ते भूतं समं भुवि न विद्यते ।
तद्यथा लभ्यते सीता तत्त्व मेवोपपादय ॥ ६
त्वय्येव हनुम! ऋस्ति बलं बुद्धिः पराक्रमः ।
देशकालानुवृत्ति श्च नय श्च नयपण्डित!" ॥ ७
ततः कार्यसमासङ्गमवगम्य हनूमति ।
विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ८
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः ।
निश्चितार्थकरश्चापि हनूमान्कार्यसाधने ॥ ९
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ १०
तं समीक्ष्य महातेजा व्यवसायोत्तरंहरिम् ।
कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११
ददौ तस्य ततः प्रीतस्स्वनामाङ्कोपशोभितम् ।
अङ्गुळीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥ १२
"अनेन त्वां हरिश्रेष्ठ! चिह्नेन जनकात्मजा ।
मत्सकाशा दनुप्राप्तमनुद्विग्नाऽनुपश्यति ॥ १३
व्यवसाय श्च ते वीर! सत्त्वयुक्त श्च विक्रमः ।
सुग्रीवस्य च संदेश स्सिद्धिं कथयतीव मे ॥" १४
स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ १५
स तत्प्रकर्षन् हरिणां महद्बलं बभूव वीरः पवनात्मजः कपिः ।
मताम्बुदे व्योम्नि विशुद्धमण्डल श्शशीव नक्षत्रगणोपशोभितः ॥१६

"अतिबल! बल माश्रितस्त्वाहं हरिवरविक्रम विक्रमै रनल्पैः ।
पवनसुत! यथाऽभिगम्यते सा जनकसुताहनुमं! स्तथा कुरुष्व ॥

इति श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशस्सर्गः ॥

॥ पञ्चचत्वारिंशस्सर्गः ॥

सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तानब्रवी द्भूयो रामकार्यार्थसिद्धये ॥ १

"एव मेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
तदुग्रशासनं भर्तु र्विज्ञाय हरिपुङ्गवाः ॥" २

शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ।
रामः प्रस्रवणे तस्मिन्नवसत्सहलक्ष्मणः ॥ ३

प्रतीक्षमाण स्तं मासं यस्सीताधिगमे कृतः ।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ॥ ४

प्रतस्थे सहसा वीरो हरिश्शतबलिस्तदा ।
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः ॥ ५

ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ।
अगस्त्यचरिता माशां दक्षिणां हरियूथपः ॥ ६

पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ७

तत स्सर्वा दिशो राजा चोदयित्वा यथा तथम् ।
कपिसेनापतीन्मुख्यान्मुमोद सुखितस्सुखम् ॥ ८

एवं संबोधिता स्सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिश मभिप्रेत्य त्वरिता स्संप्रतस्थिरे ॥ ९
आनयिष्यामहे सीतां हनिष्याम श्च रावणम् ।
नदन्त श्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ १०
क्ष्वेळन्तो धावमाना श्च विनदन्तो महाबलाः ।
'अह मेको हनिष्यामि रावणं प्राप्त माहवे ॥ ११
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ।
वेपमानां श्रमेणाद्य भवद्भिः स्थीयता मिह ॥' १२
'एक एवाहरिष्यामि पाताळादपि जानकीम् ।
विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन् ॥ १३
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ।
अहं योजनसंख्यायाः प्लविता नात्र संशयः ॥ १४
शतं योजनसंख्याया श्शतं समधिकं ह्यहम् ।
भूतले सागरे वापि शैलेषु च वनेषु च ॥ १५
पाताळस्यापि वा मध्ये न ममाऽच्छिद्यते गतिः ।
इत्येकैकं तदा तत्र वानरा बलदर्पिताः ॥ १६
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ।

इति श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशस्सर्गः ॥

॥ षट्चत्वारिंशस्सर्गः ॥

गतेषु वानरेन्द्रेषु राम स्सुग्रीव मब्रवीत् ।
"कथं भवान्विजानीते सर्वं वै मण्डलं भुवः ॥" १

सुग्रीवस्तु ततो राम मुवाच प्रणतात्मवान् ।
"श्रूयतां सर्व माख्यास्ये विस्तरेण नरर्षभ ! ॥ २
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।
परिकालयते वाली मलयं प्रति पर्वतम् ॥ ३
तदा विवेश महिषो मलयस्य गुहां प्रति ।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ ४
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।
नच निष्क्रमते वाली तदा संवत्सरे गते ॥ ५
ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ ६
अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।
इति विभ्रान्तचित्तेन कार्याकार्यमजानता ॥ ७
शिला पर्वतसंकाशा बिलद्वारि मया वृता ।
अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति ॥ ८
ततोऽहं मागां किष्किन्धां निराशस्तस्य जीविते ।
राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥ ९
मित्रैश्च सहित स्तत्र वसामि विगतज्वरः ।
आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥ १०
ततोऽहं मददां राज्यं गौरवा द्भ्रयान्वितः ।
समां जिघांसु र्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ॥ ११
परिकालयते क्रोधाद्धावन्तं सचिवै स्सह ।
ततोऽहं वालिना तेन सानुबन्धः प्रधावितः ॥ १२

नदीश्च विविधाः पश्यन्वनानि नगराणि च ।
आदर्शतलसंकाशा ततो वै पृथिवी मया ॥ १३
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ।
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ॥ १४
पर्वतांश्च नदी रम्या स्सरांसि विविधानि च ।
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ॥ १५
क्षीरोदं सागरं चैव नित्य मप्सरसालयम् ।
परिकालयमानस्तु वालिनाऽभिद्रुत स्तदा ॥ १६
पुन रावृत्य सहसा प्रस्थितोऽहं तदा विभो ! ।
पुन रावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम् ॥ १७
दिश स्तस्मा स्ततो भूयः प्रस्थितो दक्षिणां दिशम् ।
विन्ध्यपादपसंकीर्णां चन्दनद्रुमशोभिताम् ॥ १८
द्रुमशैलां स्ततः पश्यन्भूयो दक्षिणतोऽपरान् ।
पश्चिमां च दिशं प्राप्तो वालिना समभिद्रुतः ॥ १९
संपश्य न्विविधा न्देशा नस्तं च गिरिसत्तमम् ।
प्राप्य चास्तं गिरिश्रेष्ठ मुत्तरां संप्रधावितः ॥ २०
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ।
यदा न विन्दं शरणं वालिना समभिद्रुतः ॥ २१
तदा मां बुद्धिसंपन्नो हनूमान्वाक्य मब्रवीत् ।
इदानीं मे स्मृतं राज ! न्यथा वाली हरीश्वरः ॥ २२
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ।
प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् ॥ २३

तत्र वास स्सुखोऽस्माकं निरुद्विग्नो भविष्यति ।
ततः पर्वत मासाद्य ऋश्यमूकं नृपात्मज ! ॥ २४
न विवेश तदा वाली मतङ्गस्य भया त्तदा ।
एवं मया तदा राज ! न्प्रत्यक्ष मुपलक्षितम् ॥ २५
पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ॥

इति श्रीमात्किष्किन्धाकाण्डे षट्चत्वारिंशस्सर्गः ॥

॥ सप्तचत्वारिंशस्सर्गः ॥

दर्शनार्थं तु वैदेह्या स्सर्वतः कपियूथपाः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मु रञ्जसा ॥ १
सरांसि सरितः कक्षा नाकाशं नगराणि च ।
नदीं दुर्गां स्तथा शैला न्विचिन्वन्ति समन्ततः ॥ २
सुग्रीवेण समाख्याता स्सर्वे वानरयूथपाः ।
प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान् ॥ ३
विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥ ४
सर्वर्तुकामान् देशेषु वानरा स्सफलान् द्रुमान् ।
आसाद्य रजनीं शय्यां चक्रु स्सर्वेष्वहस्सु ते ॥ ५
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।
कपिराजेन संगम्य निराशाः कपियूथपाः ॥ ६
विचित्य तु दिशं पूर्वां यथोक्तां सचिवै स्सह ।
अदृष्ट्वा विनत स्सीता माजगाम महाबलः ॥ ७

उत्तरां च दिशं सर्वां विचित्य स महाकपिः ।
आगत स्सह सैन्येन वीर श्शतबलि स्तदा ॥ ८
सुषेणः पश्चिमा माशां विचित्य सह वानरैः ।
समेत्य मासे संपूर्णे सुग्रीव मुपचक्रमे ॥ ९
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
असीनं सह रामेण सुग्रीव मिद मब्रवीत् ॥ १०
" विचिताः पर्वता स्सर्वे वनानि गहनानि च ।
निम्नगा स्सागरान्ताश्च सर्वे जनपदाश्च ये ॥ ११
गुहाश्च विचिता स्सर्वा स्त्वया याः परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसंततताः ॥ १२
गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ १३
[ये चैव गहना देशा विचितास्ते पुनः पुनः ॥]
उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः ।
दिशं तु यामेव गता तु सीता ता मास्थितो वायुसुतो हनूमान् ॥"

इति श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशस्सर्गः ॥

॥ अष्टचत्वारिंशस्सर्गः ॥

सह ताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः ।
सुग्रीवेण यथोद्दिष्टं तं देश मुपचक्रमे ॥ १
स तु दूर मुपागम्य सर्वैस्तैः कपिसत्तमैः ।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ २

पर्वताग्रान्नदीदुर्गात्सरांसि विपुलान्द्रुमान् ।
वृक्षषण्डांश्च विविधा न्पर्वतान्घनपादपान् ॥ ३
अन्वेषमाणा स्ते सर्वे वानरा स्सर्वतोदिशम् ।
न सीतां ददृशु र्वीरा मैथिलीं जनकात्मजाम् ॥ ४
ते भक्षयन्तो मूलानि फलानि विविधानि च ।
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ॥ ५
स तु देशो दुरन्वेषो गुहागहनवान्महान् ।
निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम् ॥ ६
त्यक्त्वातु तं तदा देशं सर्वे वै हरियूथपाः ।
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ॥ ७
देश मन्यं दुराधर्षं विविशु श्चाकुतोभयाः ।
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ॥ ८
निस्तोया स्सरितो यत्र मूलं यत्र सुदुर्लभम् ।
न सन्ति महिषा यत्र न मृगा न च हस्तिनः ॥ ९
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ।
न यत्र वृक्षा नौषध्यो न लता नापि वीरुधः ॥ १०
स्निग्धपत्रास्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ।
प्रेक्षणीया स्सुगन्धा श्च भ्रमरै श्चापि वर्जिताः ॥ ११
कण्डु र्नाम महाभाग स्सत्यवादी तपोधनः ।
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ १२
तस्य तस्मिन्वने पुत्रो बालष्षोडशवार्षिकः ।
प्रणष्टो जीवितान्ताय क्रुद्ध स्तत्र महामुनिः ॥ १३

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ।
अशरण्यं दुराधर्षं मृगपक्षि विवर्जितम् ॥ १४

तस्य ते काननान्तां श्च गिरीणां कन्दराणि च ।
प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥ १५

तत्र चापि महात्मानो नापश्यन्जनकात्मजाम् ।
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १६

ते प्रविश्याऽशु तं भीमं लतागुल्मसमावृतम् ।
ददृशुः क्रूरकर्माणं मसुरं सुरनिर्भयम् ॥ १७

तं दृष्ट्वा वानरा घोरं स्थितं शैल मिवापरम् ।
गाढं परिहिता स्सर्वे दृष्ट्वा तान्पर्वतोपमान् ॥ १८

सोऽपि तान्वानरा न्सर्वान् 'नष्टास्थे त्यब्रवी द्बली ।
अभ्यधावत संक्रुद्धो मुष्टि मुद्यम्य संहितम् ॥ १९

तमापतन्तं सहसा वालिपुत्रोऽङ्गद स्तदा ।
रावणोऽ य मिति ज्ञात्वा तलेनाभिजघान ह ॥ २०

स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।
असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ २१

तेऽपि तस्मि न्निरुच्छ्वासे वानरा जितकाशिनः ।
व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ २२

विचितं तु ततःकृत्वा सर्वे ते काननं पुनः ।
अन्यदेवापरं घोरं विविशु र्गिरिगह्वरम् ॥ २३

ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।
एकान्ते वृक्षमूले तु निषेदु र्दीनमानसाः ॥ २४

इति श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशस्सर्गः ॥

॥ एकोनपञ्चाशस्सर्गः ॥

अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् ।
परिश्रान्तो महाप्राज्ञ स्समाश्वास्य शनैर्वचः ॥ १

वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दर्यो गिरिगुहा श्चैव विचितानि समन्ततः ॥ २

तत्र तत्र सहास्माभि र्जानकी न च दृश्यते ।
तद्वारक्षो हृता येन सीता सुरसुतोपमा ॥ ३

कालश्च नो महान्यात स्सुग्रीवश्चोग्रशासनः ।
तस्मा द्भवन्त स्सहिता विचिन्वन्तु समन्ततः ॥ ४

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥ ५

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः।
कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् ॥ ६

अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः ! ।
खेदं त्यक्त्वा पुन स्सर्वै र्वनमेत द्विचीयताम् ॥ ७

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ।
अलं निर्वेद मागम्य न हि नो मीलनं क्षमम् ॥ ८

सुग्रीवः कोपनो राजा तीक्ष्णदण्ड श्च वानरः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९

हितार्थं मेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां वा क्षमं यन्न स्सर्वेषा मेव वानराः ! " १०

अङ्गदस्य वच श्रुत्वा वचनं गन्धमादनः ।
उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११
"सदृशं खलु वो वाक्य नङ्गदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियता मस्य भाषितम् ॥ १२
पुन र्मार्गामहे शैलान्कन्दरांश्च नदीस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनं सर्वं गिरिदुर्गाणि सर्वशः ॥" १४
तत स्समुत्थाय पुन र्वानरा स्ते महाबलाः ।
विन्ध्यकाननसंकीर्णां विचेरु र्दक्षिणां दिशम् ॥ १५
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं दरीमन्त मधिरुह्य च वानराः ॥ १६
तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च ।
व्यचिन्वंस्ते हरिवरा स्सीतादर्शनकाङ्क्षिणः ॥ १७
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ १८
ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् ।
अवारोहन्त हरयो वीक्षमाणा स्समन्ततः ॥ १९
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ २०
ते मुहूर्तं समाश्वस्ताः किंचिद्भ्रमपरिश्रमाः ।
पुन रेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ २१

हनूमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः ।
विन्ध्यमेवादितस्तावद्विचेरु स्ते समन्ततः ॥ २२

इति श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशस्सर्गः ॥

॥ पञ्चाशस्सर्गः ॥

सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः ।
विचिनोति स्म विन्ध्यस्य गुहा श्च गहनानि च ॥ १

सिंहशार्दूलजुष्टेषु शिलाश्च सरित स्तथा ।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ २

आसेदु स्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ ३

सहि देशो दुरन्वेषो गुहागहनवान्महान् ।
तत्र वायुसुत स्सर्वं विचिनोति स्म पर्वतम् ॥ ४

परस्परेण हनुमानन्योन्यस्याविदूरतः ।
गजो गवाक्षो गवयश्शरभो गन्धमादनः ॥ ५

मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवान्नलः ।
अङ्गदो युवराजश्च तारश्च वनगोचरः ॥ ६

गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ ७

दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः ॥ ८

अवकीर्णं लतावृक्षै र्ददृशु स्ते महाबिलम् ।
ततः क्रौञ्चाश्च हंसाश्च सारसाश्च विनिष्क्रमन् ॥ ९
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ।
ततस्तद्बिलमासाद्य सुगन्धिदुरतिक्रमम् ॥ १०
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।
संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः ॥ ११
अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः ।
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ॥ १२
दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ।
ततः पर्वतकूटाभो हनुमान्पवनात्मजः ॥ १३
अब्रवीद्वानरांत्सर्वान्कान्तारवनकोविदः ।
गिरिजालावृतान्देशा न्मार्गित्वा दक्षिणां दिशम् ॥ १४
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ।
अस्माच्चापि बिला द्धंसाः क्रौञ्चाश्च सह सारसैः ॥ १५
जलार्द्राश्चक्रबाकाश्च निष्पतन्तिस्म सर्वतः ।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ॥ १६
तथा चेमे बिलद्वारि स्निग्धास्तिष्ठन्ति पादपाः ।
इत्युक्त्वा तद्बिलं सर्वे विविशुस्तिमिरावृतम् ॥ १७
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ।
निशाम्य तस्मात्सिंहांश्च त्रस्तांश्च मृगपक्षिणः ॥ १८
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ॥ १९

वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।
ते प्रविष्टास्तु वेगेन तद्विलं कपिकुञ्जराः ॥ २०
प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ।
ततस्तस्मिन्बिले दुर्गे नानापादपसङ्कुले ॥ २१
अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ।
ते नष्टसंज्ञास्तृषितास्संभ्रान्तास्सलिलार्थिनः ॥ २२
परिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः ।
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥ २३
आलोकं ददृशुर्वीरा निराशा जीविते तदा ।
ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ॥ २४
ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् ।
सालांस्तालांश्च पुन्नागान्ककुभान्वंजुलान्धवान् ॥ २५
चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।
स्तबकैः काञ्चनैश्चित्रैः रक्तैः किसलयैस्तथा ॥ २६
आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।
तरुणादित्यसंकाशान्वैडूर्यकृतवेदिकान् ॥ २७
विभ्राजमानान्वपुषा पादपांश्च हिरण्मयान् ।
नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः ॥ २८
महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः ।
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ॥ २९
नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः ।
काञ्चनानि विमानानि राजतानि तथैव च ॥ ३०

तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।
हैमराजतभौमानि वैडूर्यमणिमन्ति च ॥ ३१

ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः ।
पुष्पितान्फलिनो वृक्षान्प्रवाळमणिसन्निभान् ॥ ३२

काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।
मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥ ३३

महार्हाणि च यानानि ददृशुस्ते समन्ततः ।
हैमराजतकांस्यानां भाजनानां च संचयान् ॥ ३४

अगरूणां च दिव्यानां चन्दनानां च संचयान् ।
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ ३५

महार्हाणि च पानानि मधूनि रसवन्ति च ।
दिव्यानामम्बराणां च महार्हाणां च संचयान् । ३६

कम्बलानां च चित्राणामाजिनानां च संचयान् ।
तत्र तत्र च विन्यस्तान्दीप्तान्वैश्वानरप्रभान् ॥ ३७

ददृशुर्वानराश्शुभ्रान्जातरूपस्य संचयान् ।
तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः ॥ ३८

ददृशुर्वानराश्शूराः स्त्रियं कांचिददूरतः ।
तां दृष्ट्वा भृशसन्त्रस्ता श्चीरकृष्णाजिनाम्बराम् ॥ ३९

तापसीं नियताहारां ज्वलन्तीमिव तेजसा ।
विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः ॥ ४०

पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ।'

ततो हनूमान्गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।
पप्रच्छ 'का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ ४१

इति श्रीमत्किष्किन्धाकाण्डे पञ्चाशस्सर्गः ॥

॥ एकपञ्चाशस्सर्गः ॥

इत्युक्ता हनुमां स्तत्र पुनः कृष्णाजिनाम्बराम् ।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १

"इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २

महद्धरण्याविवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान् ॥ ३

दृष्ट्वा वयं प्रव्यथितास्संभ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चनावृक्षास्तरुणादित्यसन्निभाः ॥ ४

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५

तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्यास्सुरभिगन्धिनः ॥ ६

इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले ॥ ७

कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः ।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ ८

अजानतां नस्सर्वेषां सर्वमाख्यातुमर्हसि।"
एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ ९
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता।
"मयो नाम महातेजा मायावी दानवर्षभः ॥ १०
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्।
पुरा दानवमुख्यानां विश्वकर्मा बभूवह ॥ ११
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ॥ १२
पितामहाद्वरं लेभे सर्वमौशनसं धनम्।
वनं विधाय बलवांस्सर्वकामेश्वरस्तदा ॥ १३
उवास सुखितः कालं कंचिदस्मिन्महावने।
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥ १४
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः।
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥ १५
शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम्।
दुहिता मेरुसावर्णेरहं तस्यास्स्वयं प्रभा ॥ १६
इदं रक्षामि भवनं हेमाया वानरोत्तम।
मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ १७
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्।
किं कार्यं कस्य वा हेतोः कान्तारानि प्रपद्यथ ॥ १८
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्।
इमान्यभ्यवहार्याणि मूलानि च फलानि च ॥ १९

भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ।"
[एवमुक्ते शुभे वाक्ये तापस्या धर्मसंहिते ॥ २०
हनूमान्हरिशार्दूलः प्रत्युवाच स्वयंप्रभाम् ।
अधीनाः स्म स्वदर्थे च स्मर धर्ममनुत्तमम् ॥ २१
म्रियमाणान्निराहारान्संजीवय तपोधने ।
तच्छ्रुत्वा वचनं तस्य तापसी धर्मचारिणी ॥ २२
आदाय फलमूलानि विधिनोपजहार सा ।
प्रतिगृह्य तु तत्तस्यास्तदा विन्ध्यवनेचराः ॥ २३
क्षुधार्ता भक्षयामासुः प्रशशंसु स्तपोधनाम् ।]

इति श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशस्सर्गः ॥

॥ द्विपञ्चाशस्सर्गः ॥

अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् ।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १
"वानरा! यदि वः खेदः प्रणष्टः फलभक्षणात् ।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥" २
तस्यास्तद्वचनं श्रुत्वा हनूमान्मारुतात्मजः ।
आर्जवेन यथा तत्त्वमाख्यातुमुपचक्रमे ॥ ३
"राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
रामो दाशरथिश्श्रीमान्प्रविष्टो दण्डकावनम् ॥ ४
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ५

वीरस्तस्य सखा राज्ञ स्सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।
सहैभिर्वानरैर्घोरैरुद्दप्रमुखैर्वयम् ॥ ७
रावणं सहितास्सर्वे राक्षसं कामरूपिणम् ।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ८
विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥ ९
विवर्णवदनास्सर्वे सर्वे ध्यानपरायणाः ।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ १०
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् ।
लतापादपसंछन्नं तिमिरेण समावृतम् ॥ ११
असाद्धंसा जलक्लिन्नाः पक्षै स्सलिलविस्रवैः ।
कुरारास्सारसाश्चैव निष्पतन्ति पतत्रिणः ॥ १२
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ १३
'गच्छाम प्रविशा 'मेति भर्तृकार्यत्वरान्विताः ।
ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ॥ १४
इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् ।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ १५
त्वां चैवोपगतास्सर्वे परिद्यूना बुभुक्षिताः ।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ १६

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ।
यत्त्वया रक्षितास्सर्वे म्रियमाणा बुभुक्षया ॥ १७
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।"
एवमुक्ता तु धर्मज्ञैर्वानरैस्तैस्स्वयंप्रभा ॥ १८
प्रत्युवाच ततस्सर्वानिदं वानरपुङ्गवान् ।
"सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम् ॥ १९
चरन्त्या मम धर्मेण न कार्यमिह केनचित् ।"

इति श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशस्सर्गः ॥

॥ त्रिपञ्चाशस्सर्गः ॥

एवमुक्तश्शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥ १
"शरणं त्वां प्रपन्नास्स्मस्सर्वे वै धर्मचारिणि! ।
यः कृतस्समयोऽस्माकं सुग्रीवेण महात्मना ॥ २
स च कालो ह्यतिक्रान्तो विले च परिवर्तताम् ।
सा त्वमस्माद्विलाद्घोरादुत्तारयितुमर्हसि ॥ ३
तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ।
त्रातुमर्हसि नस्सर्वान्सुग्रीवभयकर्शितान् ॥ ४
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः ॥" ५
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
"जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ ६

तपसस्तु प्रभावेन नियमोपार्जितेन च ।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥ ७
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ! ।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥" ८
ततस्संमीलितास्सर्वे सुकुमाराङ्गुळैः करैः ।
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ॥ ९
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ १०
ततस्तान्वानरांत्सर्वांस्तापसी धर्मचारिणी ।
निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ ११
"एष विन्ध्यो गिरिश्श्रीमान्नानाद्रुमलताकुलः ।
एष प्रस्रवणश्शैलस्सागरोऽयं महोदधिः ॥ १२
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।"
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा ॥ १३
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ॥ १४
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ १५
विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे ।
उपविश्य महाभागाश्चिन्तामापेदिरे तदा ॥ १६
ततः पुष्पातिभाराग्रान् लताशतसमावृतान् ।
द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥ १७

तेवसन्तमनुप्राप्तं प्रतिबुद्धा परस्परम् ।
नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥ १८
ततस्तान्कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः ।
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ १९
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञः अङ्गदो वाक्यमब्रवीत् ॥ २०
"शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥ २१
वयमाश्वयुजे मासि कालसंख्यां व्यवस्थिताः ।
प्रस्थितास्सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ २२
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः ।
हितेष्वभिरता भर्तुर्निसृष्टास्सर्वकर्मसु ॥ २३
कर्मस्वप्रतिमास्सर्वे दिक्षु विश्रुतपौरुषाः ।
मां पुरस्कृत्य निर्याता पिङ्गाक्षप्रतिचोदिताः ॥ २४
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ।
हरिराजस्य संदेशमकृत्वा कस्सुखी भवेत् ॥ २५
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ २६
तीक्ष्णःप्रकृत्या सुग्रीवस्त्वभिभावे व्यवस्थितः ।
न क्षमिष्यति नस्सर्वानपराधकृतो गतान् ॥ २७
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥ २८

त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
ध्रुवं नो हिंसिताराजा सर्वान्प्रतिगतानितः ॥ २९
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ।
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ॥ ३०
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ।
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ॥ ३१
घातयिष्यति दण्डेण तीक्ष्णेन कृतनिश्चयः ।
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ॥ ३२
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ।"
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ॥ ३३
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ।
"तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ॥ ३४
[समीक्ष्याकृतकार्यांस्तु तस्मिंस्तु समये गते।
अदृष्टायां तु वेदेह्यां दृष्ट्वाऽस्मांश्च समागतान् ॥ ३५
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ ३६
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ।
नोचेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ॥ ३७
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
"अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ ३८
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् ।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा ॥" ३९

श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः ।
"यथा न हिंस्येम तथाविधानमसक्तमद्यैव विधीयतां नः" ४०

इति श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशस्सर्गः ॥

॥ चतुःपञ्चाशस्सर्गः ॥

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।
अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १

बुध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।
चतुर्दशगुणं मेने हनुमान्वालिनस्सुतम् ॥ २

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ३

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।
शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥ ४

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् ।
अभिसंधातुमारेभे हनूमानङ्गदं ततः ॥ ५

स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।
भेदयामास तांस्सर्वान्वानरान्वाक्यसंपदा ॥ ६

तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् ।
भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ॥ ७

त्वं समर्थतरः पित्रा युद्धे तारेय ! वै धुरम् ।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८

नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव ।
नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विनात्वया ॥ ९
त्वां नैते ह्यतियुञ्जीयुः प्रत्यक्षं प्रवदामि ते ।
यथाऽयं जाम्बवान्नीलस्सुहोत्रश्च महाकपिः ॥ १०
न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ।
दण्डेन वा त्वया शक्या स्सुग्रीवादपकर्षितुम् ॥ ११
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ १२
यां चेमां मन्यसे धात्रीमेतद्विलमिति श्रुतम् ।
एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे ॥ १३
स्वल्पं पि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।
लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा ॥ १४
लक्ष्मणस्य तु नाराचा बहवस्सान्ति तद्विधाः ।
वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥ १५
अवस्थाने यदैव त्वमासिष्यसि परन्तप ।
तदैव हरयस्सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १६
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ १७
स त्वं हीनस्सुहृद्भिश्च हितकामैश्च बन्धुभिः ।
तृणादपि भृशोद्विग्नस्स्पन्दमानाद्भविष्यसि ॥ १८
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।
अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ १९

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ २०
धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।
शुचिस्सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥ २१
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।
तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद ! गम्यताम् ॥" २२

इति श्रीमत्किष्किन्धाकाण्डे चतुःपञ्चाशस्सर्गः ॥

॥ पञ्चपञ्चाशस्सर्गः ॥

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।
स्वामिसत्कारसंयुक्तमङ्गदोवाक्यमब्रवीत् ॥ १
"स्थैर्यमात्ममनश्शौचमानृशंस्यमथार्जवम् ।
विक्रमश्चैव धैर्यं च सुग्रीवेनोपपद्यते ॥ २
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ ३
कथं स धर्मं जानीते येन भ्रात्रा महात्मना ।
युद्धायाभिनियुक्तेन विलस्य पिहितं मुखम् ॥ ४
सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ ५
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ।
आदिष्टा मार्गितुं सीता धर्मज्ञस्मिन्कथं भवेत् ॥ स्त ६

तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ।
आर्यः को विश्वसे ज्ञातु तत्कुलीनो जिजीविषुः ॥ ७
राज्ये पुत्रः प्रतिष्ठाप्य स्सगुणो निर्गुणोऽपि वा ।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ८
भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ।
किष्किन्धां प्राप्य जीवेय मनाथ इव दुर्बलः ॥ ९
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् ।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १०
बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् ।
अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥ ११
अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ।
इहैव प्रायमासिष्ये श्रेयो मरण मेव मे ॥ १२
अभिवादनपूर्वं हि राघवौ बलशालिनौ ।
[वाच्यौ मद्वचनाद्वीराः कुशलं रघुपुङ्गवौ ॥] १३
अभिवादनपूर्वं तु राजा कुशल मेव च ।
वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ १४
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ।
मातरं चैव मे तारामाश्वासयितुमर्हथ ॥ १५
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ।
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् । १६
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ।
विवेश चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः ॥ १७

तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ।
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ १८

सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ।
परिवार्याङ्गदं सर्वे व्यवसन्प्रायमासितुम् ॥ १९

मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ।
उपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन् ॥ २०

दक्षिणाग्रेषु दर्भेषु उदक्तीरं समास्थिताः ।
मुमूर्षवो हरिश्रेष्ठा एतत्क्षममितिस्मह ॥ २१

रामस्य वनवासं च क्षयं दशरथस्य च ।
जनस्थानवधं चैव वधं चैव जटायुषः ॥ २२

हरणं चैव वैदेह्या वालिनश्च वधं रणे ।
रामकोपं च वदतां हरीणां भयमागतम् ॥ २३

स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ।
बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥

इति श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशस्सर्गः ॥

॥ षट्पञ्चाशस्सर्गः ॥

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले ।
हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १

संपातिर्नाम नाम्ना तु चिरंजीवी विहङ्गमः ।
भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥ २

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।
उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ३
"विधिः किल नरं लोके विधानेनानुवर्तते ।
यथाऽयं विहितो भक्ष्यश्चिरान्मह्य मुपागतः ॥ ४
परंपराणां भक्षिष्ये वानराणां मृतं मृतम् ।"
इत्वाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ॥ ५
तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ।
अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥ ६
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।
इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ७
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।
हरीणामियमज्ञाता विपत्तिस्सहसाऽऽगता ॥ ८
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।
गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ ९
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥ १०
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः ।
तेन तस्योपकारार्थं त्यजताऽऽत्मान मात्मना ॥ ११
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ।
राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ॥ १२
कान्तारागि प्रपन्नाः स्मः न च पश्याम मैथिलीम् ।
स सुखी गृध्रराजस्तु रावणेन हतो रणे ॥ १३

मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ।
जटायुषो विनाशेन राज्ञो दशरथस्य च ॥ १४
हरणेन च वैदेह्यास्संशयं हरयो गताः ।
रामलक्ष्मणयोर्वासः अरण्ये सह सीतया ॥ १५
राघवस्य च बाणेन वालिनश्च तथा वधः ।
रामकोपादशेषाणां राक्षसानां तथा वधः ॥ १६
कैकेय्या वरदानेन इदं हि विकृतं कृतम् ।
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ।
भृशचलितमतिर्महामतिः कृपण मुदाहृतवान्सगृध्रराट् ॥ १७
तत्तु श्रुत्वा तदा वाक्य मङ्गदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १८
"कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ १९
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ २०
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ २१
अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ! ॥ २२
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
तस्यैव च मम भ्रातुस्सखा दशरथः कथम् ॥ २३

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ २४
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ।"

इति श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशस्सर्गः ॥

॥ सप्तपञ्चाशस्सर्गः ॥

शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ १
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ।
चक्रुर्बुद्धिं तदा रौद्रां "सर्वान्नो भक्षयिष्यति ॥ २
सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥" ३
एतां बुद्धिं ततश्चक्रुस्सर्वे ते वानरर्षभाः ।
अवतार्य गिरेश्शृङ्गाद्गृध्रमाहाङ्गदस्तदा ॥ ४
"बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ।
ममार्यः पार्थिवः पक्षिन्! धार्मिकस्तस्य चात्मजौ ॥ ५
सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।
लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम ॥ ६
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।
रामो दाशरथिश्श्रीमान्प्रविष्टो दण्डकावनम् ॥ ७
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
पितुर्निदेशनिरतो धर्म्ये पन्थानमाश्रितः ॥ ८

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्॥ ९

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ।
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ॥ १०

परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ।
एवं गृध्रो हतस्तेन रावणेन बलीयसा ॥ ११

संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ।
ततो मम पितृव्येण सुग्रीवेण महात्मना ॥ १२

चकार राघवस्सख्यं सोऽब्रवीत्पितरं मम ।
मम पित्रा विरुद्धो हि सुग्रीवस्सचिवैस्सह ॥ १३

निहत्य वालिनं रामस्ततस्तमभिषेचयत् ।
स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ १४

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ॥ १५

वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ।
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ १६

अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं विलम् ।
मयस्य मायाविहितं तद्विलं च विचिन्वताम् ॥ १७

व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ।
ते वयं कपिराजस्य सर्वे वचनकारिणः ॥ १८

कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ।

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९

इति श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशस्सर्गः ॥

॥ अष्टपञ्चाशस्सर्गः ॥

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।
सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः ॥ १
"यवीयान्मम स भ्राता जटायुर्नाम वानराः! ।
यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २
वृद्धभावादपक्षत्वाच्छ्लृण्वंस्तदपि मर्षये ।
न हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३
पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ।
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४
आवृत्याऽकाशमार्गं तु जवेन स्म गतौ भृशम् ।
मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ ५
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ।
पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः ॥ ६
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः! ।
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥" ७
जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ।
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्ततः ॥ ८

" जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।
आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ ९
अदीर्घदर्शिनं तं वै रावणं राक्षसाधिपम् ।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥" १०
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।
आत्मानुरूपं वचनं वानरांत्संप्रहर्षयन् ॥ ११
" निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः ! ।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ १२
जानामि वारुणान्लोकान्विष्णोस्त्रैविक्रमानपि ।
महासुरविमर्दान्वा ह्यमृतस्य च मन्थनम् ॥ १३
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।
जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ १४
तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।
ह्रीयमाणा मया दृष्टा रावणेन दुरात्मना ॥ १५
क्रोशन्ती 'रामरा'मेति 'लक्ष्मणे'ति च भामिनी ।
भूषणान्यपविध्यन्ती गात्राणि च विधून्वती ॥ १६
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।
असिते राक्षसे भाति यथा वा तटिदम्बुदे ॥ १७
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ १८
पुत्रो विश्रवसस्साक्षाद्भ्राता वैश्रवणस्य च ।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ १९

इतो द्वीपस्समुद्रस्य संपूर्णे शतयोजने ।
तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥ २०
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः ।
प्राकारेणार्कवर्णेन महता सुसमावृता ॥ २१
तस्यां वसति वैदेही दीना कौशेयवासिनी ।
रावणान्तःपुरे रुद्धा राक्षसीभिस्सुरक्षिता ॥ २२
जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ।
लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ २३
संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् ।
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ॥ २४
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ! ।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ २५
आद्यः पन्थाः कुलिङ्गानां येचान्ये धान्यजीविनः ।
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २६
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैस्सह ।
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥ २७
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥ २८
वैनतेयाश्च नो जन्म सर्वेषां वानरर्षभाः ।
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥ २९
अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ।
तस्मादाहारवीर्येण निसर्गेण च वानराः ॥ ३०

आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ।
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ॥ ३१
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ।
गर्हितं तु कृतं कर्म येन स्म पिशिताशिना ॥ ३२
प्रतिकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ।
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ॥ ३३
[द्वीपे द्वीपे समुद्रस्य विविधानि हि सन्ति वै ।
याव न्नगच्छेत्स तया साध्व्या सार्धं प्लवङ्गमाः !] ॥ ३४
अभिगम्य तु वैदेहीं समृद्ध्यर्थं गमिष्यथ ।
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ॥ ३५
प्रदास्याम्युदकं भ्रातुस्स्वर्गतस्य महात्मनः ।"
ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ॥ ३६
निर्दग्धपक्षं संपातिं वानराः सुमहौजसः ।
पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् ॥ ३७
बभूवुर्वानरा हृष्टाः प्रवृत्तिं मुपलभ्य ते ।

इति श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशस्सर्गः ॥

॥ एकोनषष्टितमस्सर्गः ॥

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य मुदिताहृष्टास्ते वचः प्लवगर्षभाः ! ॥ १
जाम्बवान्वानरश्रेष्ठस्सह सर्वैः प्लवङ्गमैः ।
भूतलात्सहसोत्थाय गृध्रराजमथाब्रवीत् ॥ २

"क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवांस्सर्वं गतिर्भव वनौकसाम् ॥ ३
को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥" ४
स हरीन्प्रीतिसंयुक्तांत्सीताश्रुतिसमाहितान् ।
पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् ॥ ५
"श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाऽख्यातं यत्र वाऽयतलोचना ॥ ६
अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ७
तं मामेवं गतं पुत्रस्सुपार्श्वो नाम नामतः ।
आहारेण यथा कालं बिभर्ति पततां वरः ॥ ८
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ ९
स कदाचित्क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः ।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ १०
स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।
क्षुत्पिपासापरीतेन कुमारः पततां वरः ॥ ११
स मामाहारसंरोधात्पीडितं प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ १२
"अहं तात! यथा कालमामिषार्थी खमाप्लुतः ।
महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ॥ १३

ततस्सत्त्वसहस्राणां सागरान्तरचारिणाम् ।
पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ १४
तत्र कश्चिन्मया दृष्टस्सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयप्रभः ॥ १५
सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६
न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् ।
नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ १७
स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ।
अथाहं खेचरैर्भूतैरभिगम्य सभाजितः ॥ १८
'दिष्ट्या जीवसि ता'तेति ह्यब्रुवन्मां महर्षयः ।
'कथंचित्सकळत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥' १९
एवमुक्तस्ततोऽहं तैस्सिद्धैः परमशोभनैः ।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ २०
हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ २१
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।
एष कालात्ययस्ताव "दिति कालविदां वरः ॥ २२
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छ्रुत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ २३
अपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमे ।
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ २४

श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।
वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ॥ २५
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ।
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ॥ २६
प्रेषिताः कपिराजेन देवैरपि दुरासदाः ।
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ॥ २७
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ।
कामं खलु दशग्रीवस्तेजोबलसमन्वितः ॥ २८
भवतां तु समर्थानां न किंचिदपि दुष्करम् ।
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ॥ २९
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।"

इति श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमस्सर्गः ॥

॥ षष्टितमस्सर्गः ॥

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ १
तमङ्गदमुपासीनं तैस्सर्वैर्हरिभिर्वृतम् ।
जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत् ॥ २
"कृत्वा निश्शब्दमेकाग्राश्शृण्वन्तु हरयो! मम ।
तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥ ३
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने ।
सूर्यातपपरीताङ्गो निर्दग्धस्सूर्यरश्मिभिः ॥ ४

लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ।
वीक्षमाणो दिशस्सर्वानाभिजानामि किंचन ॥ ५
ततस्तु सागरान् शैलान्नदीस्सर्वास्सरांसि च ।
वनान्युदधिवेलां च समीक्ष्य मतिरागमत् ॥ ६
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् ।
दक्षिणस्योदधेस्तीरे विन्ध्योऽय मिति निश्चितः ॥ ७
आसीच्चात्राऽश्रमं पुण्यं सुरैरपि सुपूजितम् ।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् ॥ ८
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ।
वसतो मम धर्मज्ञा! स्स्वर्गते तु निशाकरे ॥ ९
अवतीर्य तु विन्ध्याग्रात्कृच्छ्रेण विपमाच्छनैः ।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ १०
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् ।
जटायुषा मया चैव बहुशोऽभिगतो हि सः ॥ ११
तस्याऽश्रमपदाभ्याशे ववुर्वातास्सुगन्धिनः ।
वृक्षो नापुष्पितः काश्चिदफलो वा न विद्यते ॥ १२
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।
द्रष्टुकामः प्रतीक्षेऽहं भगवन्तं निशाकरम् ॥ १३
अथापश्यमदूरस्थ मृषिं ज्वलिततेजसम् ।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ १४
तमृक्षास्सृमरा व्याघ्रास्सिंहा नागा स्सरीसृपाः ।
परिवार्योपगच्छन्ति धातारं प्राणिनो तथा ॥ १५

ततः पाप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ १६

ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः ।
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यं मपृच्छत ॥ १७

"सौम्य ! वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते ।
अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ॥ १८

गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ १९

ज्येष्ठो हि त्वं तु संपाते ! जटायुरनुजस्तव ।
मानुषं रूप मास्थाय गृहीतां चरणौ मम ॥ २०

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।
दण्डो वायं कृतः केन सर्वमाख्याहि पृच्छतः ॥" २१

इति श्रीमत्किष्किन्धाकाण्डे षष्टितमस्सर्गः ॥

॥ एकषष्टितमस्सर्गः ॥

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ।
आचचक्षे मुनेस्सर्वं सूर्यानुगमनं तदा ॥ १

भगव ! न्व्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः ।
परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥ २

अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ ।
आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ३

कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् ।
रविस्स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४
तथाऽवां युगपत्प्राप्तावपश्याव महीतले ।
रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ॥ ५
क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवे ।
गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ६
तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ ।
आवामालोकयावस्तु वनं शाद्वलसन्निभम् ॥ ७
उपलैरिव संछन्ना दृश्यते भूरिशोलचयैः ।
आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ॥ ८
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः ।
भूतले संप्राकाशन्ते नागा इव जलाशये ॥ ९
तीव्रस्स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः ।
समाविशति मोहश्च तमो मूर्छा च दारुणा ॥ १०
न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी ।
युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ ११
मनश्च मे हतं भूयस्सन्निवर्त्य तु संश्रयम् ।
यत्नेन महता ह्यस्मिन्पुनस्संधाय चक्षुषी ॥ १२
यत्नेन महता भूयो रविस्समवलोकितः ।
तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १३
जटायुर्मामनापृच्छ्य निपपात महीं ततः ।
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १४

पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते ।
प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम् ॥ १५
आशङ्के तं निपतितं जनस्थाने जटायुषम् ।
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १६
राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।
सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः ॥" १७

इति श्रीमत्किष्किन्धाकाण्डे एकषष्टितमस्सर्गः ॥

॥ द्विषष्टितमस्सर्गः ॥

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ।
अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ १
"पक्षौ तु ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।
प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ॥ २
पुराणे सुमहत्कार्यं भविष्यति मयाश्रुतम् ।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ ३
राजा दशरथो नाम काश्चिदिक्ष्वाकुनन्दनः ।
तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ ४
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।
अस्मिन्नर्थे नियुक्तस्सन्पित्रा सत्यपराक्रमः ॥ ५
नैर्ऋतो रावणो नाम तस्य भार्यां हरिष्यति ।
राक्षसेन्द्रो जनस्थानादवध्यस्सुरदानवैः ॥ ६

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।
न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ ७
परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ।
यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदंत्विति ।
अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ ९
'यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।
देवत्वं गच्छतोर्वापि तयोरन्नमिदं' त्विति ॥ १०
एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः ! ।
आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ! ॥ ११
सर्वथा हि न गन्तव्यमीदृशः क्व गमिष्यसि ।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ १२
नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।
इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ १३
त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ।
ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४
इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ ।
नेच्छे चिरं धारयितुं प्राणांस्त्वय्यक्ष्ये कळेबरम् ॥ १५
महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ।"

इति श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमस्सर्गः ॥

॥ त्रिषष्टितमस्सर्गः ॥

"एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टस्स स्वमाश्रमम् ॥ १
कन्दरात्तु विसर्पित्वा पर्वतस्य शनैश्शनैः ।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ २
अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥ ३
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम् ॥ ४
उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ॥ ५
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।
बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥ ६
पुत्रस्संतर्जितो वाग्भिर्न भ्राता मैथिली कथम् ।
तस्या विलपितं श्रुत्वा तौ च सीताविना कृतौ ॥ ७
न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम् ।"
यस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैस्सह ॥ ८
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ॥ ९
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।
"ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः ॥ १०

आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ।
यौवने वर्तमानस्य ममाऽसीद्यः पराक्रमः ॥ ११
तमेवाद्यानुगच्छामि बलं पौरुषमेव च ।
सर्वथा क्रियतां यत्नस्सीतामधिगमिष्यथ ॥ १२
पक्षलाभो ममायं वस्सिद्धिप्रत्ययकारकः ।
इत्युक्त्वा स हरींत्सर्वांत्संपातिः पतगोत्तमः ॥ १३
उत्पपात गिरेश्शृङ्गाज्जिज्ञासुः खगमां गतिम् ।"
तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ॥ १४
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ।
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखां दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ १५

इति श्रीमल्किष्किन्धाकाण्डे त्रिषष्टितमस्सर्गः ॥

॥ चतुष्षष्टितमस्सर्गः ॥

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः ।
संगताः प्रीतिसंयुक्ता विनेदुर्भीमविक्रमाः ॥ १
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।
हृष्टास्सागरमाजग्मुस्सीतादर्शनकाङ्क्षिणः ॥ २
अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ ३
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।
सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ ४

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।
व्याप्तास्यैस्सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ ५
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।
क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६
संकुलं दानवेन्द्रैश्च पाताळतलवासिभिः ।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ७
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
विषेदुस्सहसा सर्वे 'कथं कार्यं'मिति ब्रुवन् ॥ ८
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
आश्वासयामास हरीन्भयार्तान्हरिसत्तमः ॥ ९
तान्विषादेन महता विषण्णान्वानरर्षभान् ।
उवाच मतिमान्काले वालिसूनुर्महाबलः ॥ १०
"न विषादे मनः कार्यं विषादो दोषवत्तमः ।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ ११
विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति ॥" १२
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैस्सह ।
हरिवृद्धैस्समागम्य पुनर्मन्त्रममन्त्रयत् ॥ १३
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १४
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १५

ततस्तान्हरिवृद्धांश्च तत्र सैन्यमरिन्दमः ।
अनुमान्याङ्गदश्रीमान्वाक्यमर्थवदब्रवीत् ॥ १६
"क इदानीं महातेजा लङ्घयिष्यति सागरम् ।
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ १७
को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः ।
इमांश्च यूथपांत्सर्वान्मोक्षयेत्को महाभयात् ॥ १८
कस्य प्रभावादारांश्च पुत्रांश्चैव गृहाणि च ।
इतो निवृत्ताः पश्येम सिद्धार्थास्सुखिनो वयम्॥ १९
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।
अभिगच्छेम संहृष्टास्सुग्रीवं च महाबलम् ॥ २०
यदि कश्चित्समर्थो वस्सागरप्लवने हरिः ।
स ददात्विह नश्शीघ्रं पुण्यामभयदक्षिणाम् ॥" २१
अङ्गदस्य वचश्श्रुत्वा न कश्चित्किञ्चिदब्रवीत् ।
स्तिमितेवाभवत्तत्र सर्वा सा हरिवाहिनी ॥ २२
पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः ।
"सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २३
व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।
न हि वो गमने सङ्गः कदाचित्कस्यचित्कचित् ॥ २४
ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः ॥"

इति श्रीमत्किष्किन्धाकाण्डे चतुष्षष्टितमस्सर्गः ॥

॥ पञ्चषष्टितमस्सर्गः ॥

ततोऽङ्गदवचश्श्रुत्वा सर्वे ते वानरोत्तमाः ।
स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥ १
गजो गवाक्षो गवयश्शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ २
आवभाषे गजस्तत्र 'प्लवेयं दशयोजनम् ।'
गवाक्षो 'योजनान्याह गमिष्यामीति विंशतिम् ॥ ३
गवयो वानरस्तत्र वानरांस्तानुवाच ह ।
'त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ! ॥' ४
शरभस्तानुवाचाथ वानरान् वानरर्षभः ।
'चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ॥ ५
वानरस्तु महातेजा अब्रवीद्गन्धमादनः ।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥' ६
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
'योजनानां परं षष्टिमहं प्लवितुमुत्सहे' ॥ ७
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
'गमिष्यामि न संदेहस्सप्ततिं योजनान्यहम् ॥' ८
सुषेणस्तु महातेजाः प्रोक्तवान्हरिसत्तमान् ।
'अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ! ॥ ९
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत ॥ १०

"पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्ताः स्म सांप्रतम् ॥ ११
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ १२
सांप्रतं कालभेदेन या गतिस्तां निबोधत ।
नवतिं योजनानां तु गमिष्यामि न संशयः ॥" १३
तांश्च सर्वान्हरिश्रेष्ठान्जांबवान्पुनरब्रवीत् ।
"न खल्वेतावदेवासीद्गमने मे पराक्रमः ॥ १४
मया महाबलेश्चैव यज्ञे विष्णुस्सनातनः ।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥ १५
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।
यौवने च तदाऽऽसीन्मे बलमप्रतिमं परैः ॥ १६
संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ।
नैतावता हि संसिद्धिः कार्यस्यास्य भविष्यति ॥" १७
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।
अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः ॥ १८
"अहमेतद्गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिस्स्यान्नवेति न निश्चिता ॥" १९
तमुवाच हरिश्रेष्ठं जाम्बवान्वाक्यकोविदः ।
"ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ २०
कामं शतं सहस्रं वा न ह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१

न हि प्रेषयिता तात! स्वामी प्रेष्यः कथंचन ।
भवताऽयं जनस्सर्वः प्रेष्यः प्लवगसत्तम! ॥ २२
भवान्कळत्रमस्माकं स्वामिभावे व्यवस्थितः ॥
स्वामी कळत्रं सैन्यस्य गतिरेषा परन्तप! ॥ २३
तस्मात्कळत्रवत्तात! प्रतिपाल्यस्सदा भवान् ।
अपि चैतस्य कार्यस्य भवान्मूलमरिन्दम! ॥ २४
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले सति हि सिध्यन्ति गुणाः पुष्पफलादयः ॥ २५
तद्भवानस्य कार्यस्य साधने सत्यविक्रम! ।
बुद्धिविक्रमसंपन्नो हेतुरत्र परन्तप! ॥ २६
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम! ।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने" ॥ २७
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥ २८
"यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः ॥
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ २९
नह्यकृत्वा हरिपतेस्संदेशं तस्य धीमतः ।
तत्रापि गत्वा प्राणानां पश्येयमपि परिरक्षणम् ॥ ३०
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ।
अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥ ३१
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।
तद्भवानेव दृष्टार्थस्संचिन्तयितुमर्हति ॥" ३२

सोऽङ्गदेन तथा वीरः प्रत्युक्तः प्लवगर्षभः ।
जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ३३
"अस्य ते वीर! कार्यस्य न किंचित्परिहीयते ।
एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥" ३४
ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ।
संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ ३५

इति श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमस्सर्गः ॥

॥ षट्षष्टितमस्सर्गः ॥

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवांत्समुदीर्यैव हनूमन्तमथाब्रवीत् ॥ १
"वीर वानरलोकस्य सर्वशास्त्रविदां वर ।
तूष्णीमेकान्तमाश्रित्य हनूमन्किं न जल्पसि ॥ २
हनूमन्हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमस्सर्वपक्षिणाम् ॥ ४
बहुशो हि मया दृष्टस्सागरे स महाबलः ।
भुजगानुद्धरन्पक्षी महावेगो महायशाः ॥ ५
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ॥ ६

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ ८
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी ॥ १०
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ।
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ॥ ११
अचरत्पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ।
तस्या वस्त्रं विशालाक्ष्या पीतं रक्तदशं शुभम् ॥ १२
स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः ।
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ॥ १३
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ।
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ॥ १४
दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ।
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ॥ १५
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ।
सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् ॥ १६
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ।
अञ्जनाया वचःश्रुत्वा मारुतः प्रत्यभाषत ॥ १७

'न त्वां हिंसामि सुश्रोणि माभूत्ते सुभगे! भयम् ।
मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥ १८
वीर्यवान्बुद्धिसंपन्नः पुत्रस्तव भविष्यति ।
महासत्त्वो महातेजा महाबलपराक्रमः ॥ १९
लङ्घने प्लवने चैव भविष्यति हि मत्समः ।
एवमुक्त्वा ततस्तुष्टा जननी ते महाकपे ॥ २०
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ।
अभ्युत्थितं ततस्सूर्यं बालो दृष्ट्वा महावने ॥ २१
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ।
शतानि त्रीणि गत्वाऽथ योजनानां महाकपे! ॥ २२
तेजसा तस्य निर्धूतो न विषादं ततो गतः ।
तावदापततस्तूर्णमन्तरिक्षं महाकपे! २३
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ।
तदा शैलाग्रशिखरे वामो हनु रभज्यत ॥ २४
ततो हि नामधेयं ते हनूमानिति कीर्त्यते ।
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहस्स्वयम् ॥ २५
त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ।
संभ्रान्ताश्च सुरास्सर्वे त्रैलोक्ये क्षोभिते सति ॥ २६
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ।
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ॥ २७
अशस्त्रवध्यतां तात! समरे सत्यविक्रम! ।
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ॥ २८

सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ।
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ॥ २९

[आयुश्श्रीकीर्तिरैश्वर्यमाशिषः पुरुषस्य याः ।
भवन्त्येव हि तत्काले यथानिच्छाविपर्ययः] ॥ ३०

स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ।
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ॥ ३१

त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ।
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ॥ ३२

दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः ।
त्रिविक्रमे मया तात सशैलवनकानना ॥ ३३

त्रिस्सप्रकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ।
तथा चौषधयोऽस्माभिस्संचिता देवशासनात् ॥ ३४

निष्पन्नममृतं याभिस्तदाऽऽसीन्नो महद्बलम् ।
स इदानीमहं वृद्धःपरिहीनपराक्रमः ॥ ॥ ३५

साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ।
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमोह्यसि ॥ ३६

त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी ।
उत्तिष्ठ हरिशार्दूल ! लङ्घयस्व महार्णवम् ॥ ३७

परा हि सर्वभूतानां हनूमन् ! या गतिस्तव ।
विषण्णा हरयस्सर्वे हनूमन्किमुपेक्षसे ॥ ३८

विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव ।"

ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ॥ ३९

इति श्रीमात्किष्किन्धाकाण्डे षट्षष्टितमस्सर्गः ॥

॥ सप्तषष्टितमस्सर्गः ॥

तं दृष्ट्वा जृंभमाणं ते क्रमितुं शतयोजनम् ।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ १

सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः ।
विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ॥ २

प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः ।
त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ ३

संस्तूयमानो हनुमान्व्यवर्धत महाबलः ।
समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ॥ ४

तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः ।
तेजसा पूर्यमाणस्य रूपमासीदनुत्तमम् ॥ ५

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।
मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥ ६

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।
अम्बरीषमिवाऽदीप्तं विधूम इव पावकः ॥ ७

हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः ।
अभिवाद्य हरिन्वृद्धान्हनूमानिदमब्रवीत् ॥ ८

" आरुजन्पर्वताग्राणि हुताशनसखोऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ९
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।
मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः ॥ १०
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ ११
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ १२
ममोरुजङ्घवेगेन भविष्यति समुत्थितः ।
सम्मूर्छितमहाग्राहस्समुद्रो वरुणालयः ॥ १३
पन्नगाशनमाकाशे पतन्तं पक्षिसेविते ।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ १४
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।
अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ १५
[पृथिव्या दक्षिणं तावदुत्तरं गन्तुमुत्सहे] ।
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ॥ १६
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ।
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ॥ १७
सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ।
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः ॥ १८
हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ।
लतानां विविधं पुष्पं पादपानां च सर्वशः ॥ १९

अनुयास्यन्ति मामद्य प्लवमानं विहायसा ।
भविष्यति हि मे पन्थास्स्वातेः पन्था इवाम्बरे ॥ २०
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ।
द्रक्ष्यन्ति निपतिष्यन्तं सर्वभूतानि वानराः ॥ २१
महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ।
दिवमावृत्य गच्छन्तं प्रसमानमिवाम्बरम् ॥ २२
विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् ।
सागरं क्षोभयिष्यामि प्लवमानस्समाहितः ॥ २३
वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा ।
ऋते सुपर्णराजानं मारुतं वा महाजवम् ॥ २४
न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ।
निमेषान्तरमात्रेण निरालम्बनमम्बरम् ॥ २५
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ।
भविष्यति हि मे रूपं प्लवमानस्य सागरे ॥ २६
विष्णोर्विक्रममाणस्य पुरा त्रीन्विक्रमानिव ।
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ॥ २७
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ! ।
मारुतस्य समो वेगे गरुडस्य समो जवे ॥ २८
अयुतं योजनानां तु गमिष्यामीति मे मतिः ।
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ॥ २९
विक्रम्य सहसा हस्तादमृतं तदिहानये ।
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥ ३०

महासंहननावेतौ महान्तौ पुरुषर्षभौ ।
ऋश्यमूकात्तताश्शैलाद्वहेयं रामलक्ष्मणौ ॥ ३१
नूनमेष्यामि वैदेहीं रामस्य महिषीं प्रियाम् ।"
तमेवं वानरश्रेष्ठं गर्जन्तमभितौजसम् ॥ ३२
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ।
तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ ३३
उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमम् ।
"वीर! केसरिणः पुत्र! हनूमन्मारुतात्मज! ॥ ३४
ज्ञातीनां विपुलश्शोकस्त्वया तात! प्रणाशितः ।
तव कल्याणरुचयः कपिमुख्यास्समागताः ॥ ३५
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ।
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥ ३६
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ।
स्थास्यामश्चैकपादेन यावदागमनं तव ॥ ३७
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ।"
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ ३८
"नेयं मम मही वेगं लङ्घने धारयिष्यति ।
एतानीह नगस्यास्य शिलासंकटशालिनः ॥ ३९
शिखराणि महेन्द्रस्य स्थिराणि सुमहान्ति च ।
एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् । ४०
नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु ।
एतानि मम निष्पेषं पादयोः प्लवतां वराः! ॥ ४१

प्लवतो धारयिष्यन्ति योजनानामितश्शतम् ।"
ततस्तं मारुतप्रख्यस्स हरिर्मारुतात्मजः ॥ ४२
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ।
वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ॥ ४३
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ।
सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ॥ ४४
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ।
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ॥ ४५
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ।
पादाभ्यां पीडितस्तेन महाशैलो महात्मना ॥ ४६
ररास सिंहाभिहतो महान्मत्त इव द्विपः ।
मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः ॥ ४७
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ।
नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ ४८
उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ।
त्यज्यमानमहासानुस्संनिलीनमहोरगः ॥ ४९
चलशृङ्गशिलोद्घातस्तदाऽभूत्स महागिरिः ।
निःश्वसद्भिस्तदाऽऽर्तैस्तु भुजङ्गैरर्धनिस्सृतैः ॥ ५०
सपताक इवाभाति स तदा धरणीधरः ।
ऋषिभिस्त्रासससम्भ्रान्तैस्त्यज्यमानशिलोच्चयः ॥ ५१
सीदन्महति कान्तारे सार्थहीन इवाध्वगः ।

स वेगवान्वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ॥ ५२
मनस्समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ।

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये चतुर्विंशत्सहस्रिकायां संहितायां
किष्किन्धाकाण्डे सप्तषष्टितमस्सर्गः
श्रीमत्किष्किन्धाकाण्डस्समाप्तः

Printed by V. Ramaswamy Sastrulu & Sons, at 'Vavilla Press', Madras.